
कविकुलगुरु - कालिदास - संस्कृत - विश्वविद्यालयः

कविकुलगुरु कालिदास संस्कृत विश्वविद्यालय, रामटेक

हस्तलिखित संग्रह E

दाखल क्र M-2485 विषय वेद

नांव ऋग्वेद संहिता प्रथम अष्टक

लेखक/लिपीकार

पृष्ठ 88

काळ पूर्ण/अपूर्ण पूर्ण

M-2485

ऋग्वेद संहिता प्रथम अष्टक

॥ अथसंहिताप्रथमाष्टकप्रारंभः ॥ राम

ऋ·अ·१·मं·
१

३अग्निमी·६ ॥ ७नूचित्स·१५॥ १७वेदि२३॥ १९इच्छंति २४ ॥ १२ महिमुहे २४॥

४सुरूपकृ०८	९पृभ्वान० १२	८अबोध्यु१२	१५इंद्रंमति०२२	१२विदादिवः १९
४ एंद्रसान०७	११उपप्र० १५	१५कयाशु०३६	९इमंमहे०२२	१६आरुद्रा०२३
६अग्निंदू०१२	९प्रयेशुं० १९	१२युवोर० २०	१०त्वांह्यग्ने०२६	१५यद्द्यस्थः२३
६सोमानं· १६	१२इमंस्तो·२६	११त्वमग्ने१९	११भद्रंते० २०	१५त्वंह्यग्नेप्र·२०
७कस्यनू० १९	१०इंद्रमि० २४	११योजात २५	११ यन्नऽइंद्रः २१	८ त्वमग्नेयु २७
५त्वमग्नेप्र०१४	५नासत्या १५	१०गुणा० १९	१३प्रक्रमु० २६	२० वृषामदः २६
८प्रवोयह्वं·२०	६ कदित्था०१६	११आते० २२	१३अग्नेपि०१६	६ योरयिवः २२
७अग्नेवि०१६	७ अग्निं० ११	१२सोम० २५	१४ अबोध्यु०२२	१२ऊवेवः० २६
७अभित्यं०१४	६ आत्वाजु ७	१७प्रवो० २३	१८प्रवेधसे०२४	१४ स्तुपेनरा २५

राम
१

१अग्निंनरः ३०	१० वृयमु० ४७	७अयावी २२	१३इदमि० ३२	४त्वमग्ने द्यु ४३
१६त्वेहयत २६	१३ योयजा ३०	१९ प्रदेवम ३५	१६मद्रा अ० २६	५सोमस्यमा ६२
२२ प्रभुक्रा ३४	६इमेविप्र ३०	११प्रतआ २२	६सत्येनोत्त २६	५त्वांह्यग्नेस ५८
१५ कईंव्य०२५	१०अग्नआ ३०	७अस्यप्रे २७	९संजागृव २८	६अबोध्यग्निः ८७
१९ अपुस्त्व०२१	११योराजा० ३२	११सखाय २२	१३इंद्रद्ध्य० २५	६त्वंह्यग्नेप्र० ७५
१५प्रवीर १८	१३आहून २०	१६अग्नेवृ २४	१६तमस्युद्या ३०	६अग्निंनर १०४
५माचिद० २७	१०गोर्धय ३२	१३त्वष्टादु ३१	२३ नासदा २४	१०माचिदन्य ९२
७महाँइं० ३८	२४स्वादि० ४३	१८प्रदेव० ३९	४० शासइ ४०	७ स्वादिष्ठ ११४
८ इंद्रःसुते० ३०	३६पवस्व० ३६	८अच्छाम १४	२४अग्निमी १९१	१२अग्नेवृ०१९१

सं.प्र.प.षा. श्रीगणेशाय नमः॥ ॐ ॥अथऋग्वेदाम्नाये शाकलके सूक्तप्रतीकऋक्संख्यऋषिदैवतछंदां

१ स्यनुक्रमिष्यामो यथोपदेशं नह्येतज्ज्ञानमृते श्रौतस्मार्तकर्मप्रसिद्धिर्मंत्राणां ब्राह्मणार्षेयछंदो

दैवतविद्याजनाध्यापनाभ्यां श्रेयोधिगच्छत्येतान्यामेवानेवंविदो यातयामानि छंदांसि भवंति स्था

णुं वर्च्छति गर्तं वा पात्यते प्रमीयते वा पापीयान्भवतीति विज्ञायते॥ १ ॥अथऋषयः शतर्चिन आ

द्येमंडले ऽन्त्ये क्षुद्रसूक्तमहासूक्ताः मध्यमेषु माध्यमाः क्वचित्कथंचिद्विशेषितं ब्रह्मर्षिमंत्रि

यमनुक्तगोत्रं मांगिरसं विद्याद्यस्य वाक्यं स ऋषिर्यातेनोच्यते सा देवता यदक्षरपरिमाणं तच्छंदो

ऽर्थेप्सवऋषयो देवताश्छंदोभिरभ्यधावंस्त्रिस्र ऽएव देवताः क्षित्यंतरिक्षद्युस्थाना अग्निर्वायुः

सूर्यइत्येवं व्याहृतयः प्रोक्ता व्यस्ताः समस्तानां प्रजापतिरोंकारः सर्वदेवत्यः पारमेष्ठ्यो वा ब्राह्मो १

दैवऽआध्यात्मिकस्तत्तत्स्थानान्यास्तद्विभूतयः कर्मपृथक्त्वाद्धि पृथगभिधानस्तुतयो भ

रा पं तुत्रजापति

वंत्येकैव वा महानात्मा देवता स सूर्य इत्याचक्षते स हि सर्वभूतात्मा तदुक्तमृषिणा सूर्य आत्मा जगतस्त
स्थुषश्चेति तद्विभूतयोन्या देवतास्तदप्येतदृचोक्तमिंद्रं मित्रं वरुणमग्निमाहुरिति यथाभिधानं त्व
नुक्रमिष्यामः प्रायेणैंद्रे मरुतो राज्ञां च दानस्तुतयः ॥ २ ॥ अथ च्छंदांसि गायत्र्युष्णिगनुष्टुब्बृहती
पंक्तिस्त्रिष्टुब्जगत्यतिजगती शक्वर्यतिशक्वर्यष्ट्यत्यष्टी धृत्यतिधृतयश्चतुर्विंशत्यक्षरादीनि चतुरु
त्तराण्यूनाधिकेनैकेन निचृद्भुरिजौ द्वाभ्यां विराट्स्वराजौ पादपूरणार्थं तु क्षैप्रसंयोगैकाक्षरीभा
वान्व्यूहेदाद्येतु सप्तवर्गे पादविशेषात्संज्ञाविशेषास्ताननुक्रमं त एवोदाहरिष्यामो विराड्रूपा विरा
ट्स्थानाश्च बहूना अपि त्रिष्टुभ एवेत्युद्देशस्तत्र दशैकादशाद्वादशाक्षराणां वैराजत्रैष्टुभजा
गता इति संज्ञा अनादेशोष्टाक्षराः पादाश्चतुष्पदाश्चर्चः ॥ ३ ॥ प्रथमं छंदस्त्रिपदा गायत्री पंचकाश्च
त्वारः षट्कश्चैकश्चतुर्थश्चतुष्को वा पदपंक्तिः षट्सप्तैकादशा उष्णिग्गर्भा त्रयः सप्तकाः पादनि

चृन्मध्यमः षड्कश्चेदतिनिचृद्दशाकश्चेद्यवमध्यायस्यास्तु षड्कसप्तकाष्टकाः सावर्धमाना विपरीता
प्रतिष्ठा द्वौ षड्कौ सप्तकश्च ह्रसीयसी ॥ अयं देवायामिथैऽ अग्यागेतमद्यतामे अश्व्यानुंतावं
तः पुरुतमं ससुन्वेयऽई शाना आपः शणीतप्रेषंदश ॥ ४ ॥ द्वितीयमुष्णिक्त्रिपदांत्यो द्वादशा
ऽद्यश्चेत्पुरउष्णिङ्मध्यमश्चेत्ककुप् त्रिष्टुभजागतैश्चतुष्काः ककुम्न्यंकुशिरैकादशिनोः परः षड्क
स्तनुशिरा मध्ये चेत्पिपीलिकमध्या ऽऽद्यः पंचकस्त्रयोष्टका अनुष्टुब्गर्भा चतुःसप्तको ष्णिगेव ॥
यऽइंद्रयुंजंत्रिहरी शार्धं शार्धं वो दद्दीरेक्ष्णः प्रया घोषुहरीयस्य पितुंनुमंसीमह्युष्टो ॥ ५ ॥ तृतीय
मनुष्टुप्पंच पंचकाः षट्कश्चेत्कोमहापदपंक्तिर्जागता वष्टकश्च ह्रतिर्मध्ये चेदष्टकः पिपी राम
लिकमध्या नवकयोर्मध्ये जागतः का विराण्नववैराजं त्रयोदशौर्न ष्टरूपी दशकाः स्त्रयो वि २
राळ्के कादशकावा ॥ अग्न ओजिष्ठंनवस्वादिष्टामाकस्मेपर्युषुता विद्वांसा विष्टच्छामि प्रेद्वोऽअ

ग्नेर्ग्निंनरोष्टो॥ ६ ॥चतुर्थेबृहतीतृतीयोद्वादशाऽद्यश्चेत्पुरस्ताद्बृहतीद्वितीयश्चेन्न्यंकुसारिण्यु
रोबृहतीवास्कंधोग्रीवीवांऽत्यश्चेदुपरिष्टाद्बृहत्यष्टिनोर्मध्येदशकौविष्टारबृहतीत्रिजागतोर्ध्व
बृहतीत्रयोदशिनोर्मध्येष्टकःपिपीलिकमध्यानवकाःस्येकादश्यष्टिनोविषमपदाचतुर्नवकाबृ
हत्येव॥माचिद्न्यन्मुहोयस्पतिरीजानमिद्येपुतयंतेयुवंह्यास्तमधुयदिमेमिवोवीरंसनि
तःसुसनितस्त्वंत्वांवुयंपितोनव॥ ७ ॥पंचमंपंक्तिःपंचपदाथचतुष्पदाविराड्दशकैरयुजौ
जागतौसतोबृहतीयुजौचेद्विपरीताऽद्यौचेत्प्रस्तारपंक्तिरंत्यौचेदास्तारपंक्तिराद्यांत्यौचेत्संस्ता
रपंक्तिर्मध्यमौचेद्विष्टारपंक्तिः॥रानासोविपिप्रोरायंनरोयऽकुघस्तस्याःसमुद्रोऽआग्निंन
स्वर्दृक्तिभिःपृष्टिंसहस्राग्नेतवुश्रवोष्टो॥ ८ ॥षष्ठंत्रिष्टुब्त्रैष्टुभपदाद्वौतुजागतौयस्याःसाजा
गतेजगतीत्रैष्टुभेत्रिष्टुब्वैराजौजागतौचाभिसारिणीनवकौवैराजस्त्रैष्टुभश्चद्वौवावैराजौन

सं·अ·परि· २

वकस्त्रैष्टुभश्च विराट्स्थानैकादशिनस्त्रयोष्टकश्च विराड्रूपा द्वादशिनस्त्रयोष्टकश्च ज्योति
ष्मतीयतौ ष्टकस्त्रतो ज्योतिश्च त्वारो ष्टका जागतश्च महाबृहती मध्येचे द्यवमध्या ऽऽ द्यो दश
काव ष्टकास्त्रयः पंक्त्युत्तराविराट्पूर्वा वा॥ कस्त्वं नूनं यूपव्रस्का येवा जिनं योवा चास्त्वस्तिन
देद्रः श्रुधी हवं श्रुतं मेग्निनें द्रप्रताभिरायातेन वानां संमोतपंत्येवेंद्राग्निभ्युदादश॥
९ ॥सप्तमं जगती जागतपदी ऽष्टिनस्त्रयः स्वौ च हौ महासतोबृहत्य ष्टकौ सप्तकः षट्कोदश
कोनवकश्च षळष्टकावा महापंक्तिः॥ प्रदेव मच्छायः प्रभावियन्तिकानदं न्नायचत्वारि॥
१० ॥अथ प्रगाथाः बृहतीसतोबृहत्यो बार्हतः ककुप्चे सूर्वा काकुभो महाबृहती महासतोबृ
हत्यौ महाबार्हतो बृहती विपरीते विपरीतोत्तरौ ऽनुष्टुप्गायत्र्यौ चानुष्टुभो ऽनुष्टुप्मुखास्तृचाद् २
युक्तौ॥ अयं वां मासं खायो बृहद्भिरग्ने नहितेश्रूरातारथं पंच॥ ११ ॥सूक्तसंख्यानुवर्त

तेआन्यस्याःसूक्तसंख्यायाऋषिश्चान्यस्मादृषेरवाविशिष्टस्तुहिहवैतच्छब्दविशिष्टान्यृषिदै
वतच्छंदांसिद्विस्त्रिचतुःपंचषट्सूक्तभांजियथासंख्यमनिरुक्तासंख्याविंशतिरनादेशोत्विंद्रोदे
वतात्रिष्टुप्छंदःप्रगाथाबार्हताःविंशिकाद्विपदाविराजस्तदर्धमेकपदाःद्विर्द्विपदास्तृचःसमा
मनंत्स्ययुक्ष्वंत्याद्विपदैवंमंडलादिषाग्नेयमैंद्रात्रिष्टुबंतस्यसूक्तस्यशेषाजगत्यआदौगायत्रंश्रा
ग्धिरण्यस्तूपात्॥ १२ ॥अथपरशिष्टंपरिभाषा॥गोधाघोषाविश्ववारापालोपनिषंनिषत्॥
ब्रह्मजायाजुहूर्नामाऽगस्त्यस्यस्वसादितिः॥इंद्राणीचेंद्रमाताचसरमारोमशोर्वशी॥लोपामुद्राच
नद्यश्चयमीनारीचशाश्वती॥श्रीर्लाक्षासार्पराज्ञीवाक्श्रद्धामेधाचदक्षिणा॥रात्रीसूर्याचसावि
त्रीब्रह्मवादिन्यईरिताः॥ १३ ॥पादाअतिजगत्यांतुत्रयोद्वादशकाःपरौ॥अष्टकौशक्करीपादाः
सप्तैवाष्टाक्षरास्मृताः॥अतिशाक्करपादौद्वावादितःषोडशाक्षरौ॥जागतश्चाष्टकाबर्हिपादाः

षोळशाक्षरास्त्रयः॥ अष्टकौ चात्यष्टिपादौ जागतौ चाष्टकास्त्रयः॥ जागतश्चाष्टकश्चाथ धृतिपादौ
तु जागतौ॥ पादास्त्रयोष्टकाश्चापि षोळशाक्षर एव च॥ अष्टकश्चाथातिधृतौ द्वौ पादौ जागतौ न
तः॥ त्रयोष्टका जागतश्च तथाष्टाक्षरकावपि॥ एवं सप्तकपादास्तु प्रसंगात्त्वयमीरिताः॥ प्रवो मु
हे प्रोधं स्मैसु कं जातस्त्रिकं डुके षष्मिं होतारमुवमुंहऽ ईंद्रुस हिशाद्रौं न सप्त॥ १४ ॥अवि
दित्वा ऋषिं छंदो दैवतं गोत्रमेव च॥ यो ध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः॥ ऋषिच्छं
दो दैवतादिविज्ञानफलमुच्यते॥ ऋषिनामर्षिगोत्रज्ञ ऋषिसंस्थानतामियात्॥ ऋषेरेक
स्य विज्ञानात्सहस्त्राब्रूमृषिर्भवेत्॥ छंदसामत्रसायुज्यं छंदोज्ञानादवाप्नुयात्॥ तस्यास्तस्या
देवतायास्तद्भाव्यत्वं प्रपद्यते॥ यां यां विजानाति नरो देवतामिति निर्णये॥ जातिस्मरणसंयु
क्तो जायते यति जायते॥ ज्ञात्वा तदेतत्सूक्तेनोक्तमेतन्महात्मना॥ उक्तमन्तस्य नैष्फल्यं सर्व

कर्मसुसर्वदा॥ ऋषीणांविषयज्ञस्तुयःशारीरात्प्रमुच्यते॥ सोतीत्यतमसःपारंब्रह्मलोकेमहीयते॥
इतिकात्यायनोक्तपरिशिष्टपरिभाषा॥ ॥इतिपरिभाषासमाप्तः॥ ॥ ॐ ॥अग्निंनवम
धुच्छंदावैश्वामित्रोवायोवायव्यैंद्रवायवमैत्रावरुणास्तृचाअश्विनाद्वादशाश्विनेंद्रवैश्वदेव
सारस्वतास्तृचाःसप्तैताःप्रउगदेवताःसुरूपकृत्नुंदशैंद्रमातुयुंजंत्याद्हेत्येताःषण्मारुत्योवीळु
चिदिंद्रेणेत्यैंद्र्यौचेंद्रमिदिंद्रसानसिमिंद्रेहिगायंतिद्वादशानुष्टुभंत्विंद्रमष्टौजेतामाधुच्छंदसोऽग्निं
द्वादशमेधातिथिःकाण्वऽआग्नेयमग्निनेतिपादौद्व्याग्निदेवतौनिर्मथ्यआहवनीयश्चसुसमि
द्धइतीध्मःसमिद्धोवाग्निस्तनूनपान्नराशंसइळोबर्हिर्देवीर्द्वारउषासानक्तादैव्योहोतारौप्रचे
तसौतिस्रोदेव्यःसरस्वतीळाभारत्यस्त्वष्टावनस्पतिःस्वाहाकृतयइतिप्रत्यृचंदेवताः एतदाप्री
सूक्तमेतेनान्यान्युक्तदेवतान्येकादशकानित्वनाराशंसान्याप्रशब्दोक्तानित्वतनूनपान्त्येभि

वैश्वदेवमिंद्रसोममृतव्यंतत्रैंद्रीमारुतीत्वाष्ट्र्याग्नेय्यैंद्रीमैत्रावरुणीचतस्रोद्रविणोदसंआश्विन्या
ग्नेय्यृतुदेवताःसर्वत्रा त्वानवेंद्रावरुणयोरैंद्रावरुणंयुवाकुपादनिचृतौइंद्रोहृक्सीयसीवासोमा
नमितिपंचब्राह्मणस्पत्याश्चतुर्थ्यामिंद्रश्चसोमश्चपंचम्यांदक्षिणाचान्याःसादसस्पत्याःना
राशंसीवांत्याप्रतिस्यमाग्निमारुतं॥ १ ॥अथानुवाकप्रारंभः॥ ॥ ॐ ॥अग्निमीळेसुरूपकृ
त्नुमेंद्रसानसिमग्निंदूतंसोमानंस्वरणंकस्यनूनंत्वमग्नेप्रथमःप्रवोयह्वमग्नेविवस्वदभित्य
मेषंनूचित्सहोजाःपश्वानतायुमुपप्रयंतःप्रयेशुंभंतइमंस्तोममिंद्रंमित्रंनासत्याभ्यांकदित्था
ग्निंहोतारमात्वाजुवोवेविषदेबोध्यग्निःकयाशुभासुवीरजोंसित्वमग्नेद्युभिर्योजातएवगणा
नांत्वातेपितःसोमस्यमाप्रवोदेवायेच्छंतितेवइंद्रमतिरिमंमहेवांह्यग्नेभद्रंतेयत्त्वइंद्रःप्रकृसु ५
भ्योग्नेपिबाबोध्यग्निःप्रवेधसेमहिमहेविदादिवआरुद्रासोयदद्यस्थस्त्वंह्यग्नेप्रथमस्त्वमे

ग्नेयज्ञानांवृषामदोयोरयिंवोढुवेवःस्तुषेनराग्निंनरस्त्वेहुयत्स्रभुक्राकईंव्यक्ताअपुस्त्वसुःप्रवी
रयामाश्चिदन्यन्महांइंद्रइंद्रःसुतेषुवयमुत्वायोयजातीमेविप्रस्याग्नआयाहियोराज्ञात्वंनइं
द्रक्षुमंतंगोईंयतिस्वादिष्ठयापवस्वदक्षसाधनोयावीतीप्रदेवमच्छप्रतआश्रावोस्यप्रेषास
खायआनिषीदताग्नेबृहन्त्वष्टादुहित्रेप्रदेवत्राच्छामइंद्रमिदमित्थाभद्राअग्नेःसत्येनोत्वभि
तासंजागृवद्भिरिंद्रइद्ध्यतमस्यद्यावापृथिवीनासदासीच्छासद्वित्थेत्यनुवाकाःपंचाशीतिरेक
रात्रिरुपवसेत्त्रिरात्रंमंडलेतत्फलंब्रह्मलोकंसगच्छति॥ १॥अग्निमीळेपुरोहितमित्येका
कुषुंभकस्तदब्रवीदावदंस्त्वंशकुनेभद्रमावदगृणानाजमदग्निनाधामंतेविश्वंभुवनमधि
श्रितंगंतानेपज्ञंयज्ञियाःसुशामियोनःस्वोअरणःप्रतिचक्ष्वविचक्ष्वा ग्नेयाहिमरुत्सखाय
त्वैराजन्वृतंहविरितिह्वचाःसमानीवआकूतिरित्येका॥अथश्राकृभोजनं॥अग्निमीळेवातऽ

सं·प्र·परि· आवातुषड्वर्गोग्निंनरो ग्नेबृहन्नूपंचवर्गाःप्रहृत्वान्ययंसयस्याद्यंतंद्वेविरूपेनिहोताद्यंतांतंपस्तु
६ रितिभुक्त्वानपठेत्॥ ॥इतिप्राक्भोजनं॥ १ ॥ ॐ ॥अग्निमीळेपुरोहितंयज्ञस्यदेवमृ
त्विजं॥होतारंरत्नधातमं॥अग्निःपूर्वेभिर्ऋषिभिरीड्योनूतनैरुत॥सदेवाँएहवक्षति॥अग्नि
नारयिमश्नवत्पोषमेवदिवेदिवे॥यशसंवीरवत्तमं॥अग्नेयंयज्ञमध्वरंविश्वतःपरिभूरसि॥स
ऽइद्देवेषुगच्छति॥अग्निर्होताकविक्रतुःसत्यश्चित्रश्रवस्तमः॥देवोदेवेभिरागमत्॥ १ ॥
यदंगदाशुषेत्वमग्नेभद्रंकरिष्यसि॥तवेत्तत्सत्यमंगिरः॥उपत्वाग्नेदिवेदिवेदोषावस्तर्धिया
वयं॥नमोभरंतऽएमसि॥राजंतमध्वराणांगोपामृतस्यदीदिविं॥वर्धमानंस्वेदमे॥सनः
पितेवसूनवेऽग्नेसूपायनोभव॥सचस्वानःस्वस्तये॥ २ ॥ १ वायवायाहिदर्शतेमेसोमाऽ ६
अरंकृताः॥तेषांपाहिश्रुधीहवं॥वायउक्थेभिर्जरंतेत्वामच्छाजरितारः॥सुतसोमाऽअहर्वि

दः॥ वायो तव प्रपृंचती धेना जिगाति दाशुषे। उरूची सोमपीतये॥ इंद्रवायू ऽइमे सुता ऽउप प्रयो
भिरागतं। इंदवो वा मुशंति हि॥ वायविंद्रश्च चेतथः सुतानां वाजिनीवसू। तावायातमुपद्रवत्
॥ ३ ॥ वायविंद्रश्च सुन्वत ऽआयातमुपनिष्कृतं। मक्ष्वि१त्था धिया नरा॥ मित्रं हुवे पूतदक्षं व
रुणं च रिशादसं। धियं घृताचीं साधंता॥ ऋतेन मित्रावरुणा वृतावृधा वृतस्पृशा। क्रतुं बृहंत
माशाथे॥ कवी नो मित्रावरुणा तुविजाता ऽउरुक्षया। दक्षं दधाते ऽअपसं॥ ४ ॥ १ ॥ अश्विना य
ज्वरीरिषो द्रवत्पाणी शुभस्पती। पुरुभुजा चनस्यतं॥ अश्विना पुरुदंससा नरा शवीरया धिया।
धिष्ण्या वनतं गिरः॥ दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः। आयातं रुद्रवर्तनी॥ इंद्रायाहि
चित्रभानो सुता ऽइमे त्वायवः। अण्वीभिस्तना पूतासः॥ इंद्रायाहि धियेषितो विप्रजूतः सुतावतः।
उप ब्रह्माणि वाघतः॥ इंद्रायाहि तूतुजान ऽउप ब्रह्माणि हरिवः। सुते दधिष्व नश्चनः॥ ५ ॥

सं॰अ॰१ ओमासश्चर्षणीधृतो विश्वेदेवासऽआगत । दाश्वांसोदाशुषःसुतं ॥ विश्वेदेवासोऽअप्तुरःसुत
७ मागंतूर्णयः ॥ उस्राऽइवस्वसराणि ॥ विश्वेदेवासोऽअस्रिधऽएहिमायासोऽअद्रुहः । मेधंजुषं
तवह्नयः ॥ पावकानःसरस्वतीवाजेभिर्वाजिनीवती । यज्ञंवष्टुधियावसुः ॥ चोदयित्रीसूनृतानां
चेतंतीसुमतीनां । यज्ञंदधेसरस्वती ॥ महोऽअर्णःसरस्वतीप्रचेतयतिकेतुना । धियोविश्वावि
राजति ॥ ६ ॥ १२ अनुवाकः ॥ १ सुरूपकृत्नुमूतयेसुदुघामिवगोदुहे । जुहूमसिद्यविद्यवि
॥ उपनःसवनागहिसोमस्यसोमपाःपिब । गोदाऽइद्रेवतोमदः ॥ अथातेऽअंतमानांविद्याम
सुमतीनां । मानोऽअतिख्यऽआगहि ॥ परेहिविग्रमस्तृतमिंद्रंपृच्छाविपश्चितं ॥ यस्तेसखि
भ्यऽआवरं ॥ उतब्रुवंतुनोनिदोनिरन्यतश्चिदारत । दधानाऽइंद्रऽइद्दुवः ॥ ७ ॥ उतनःसुभ ७
गाँऽअरिर्वोचेयुर्दस्मकृष्टयः । स्यामेदिंद्रस्यशर्मणि ॥ एमाशुमाशवेभरयज्ञश्रियंनृमादनं ॥

पतयन्मंदयत्सखं॥ अस्यपीत्वाशतक्रतो घनोवृत्राणामभवः। प्रावोवाजेषुवाजिनं॥ तंत्वावाजे
षुवाजिनंवाजयामःशतक्रतो। धनानामिंद्रसातये॥ योरायोऽवनिर्महान्त्सुपारःसुन्वतःसखा
। तस्माऽइंद्रायगायत॥ ८ ॥ १ ॥ आत्वेतानिषीदतेंद्रमभिप्रगायत। सखायःस्तोमवाहसः॥
पुरूतमंपुरूणामीशानंवार्याणां। इंद्रंसोमेसचासुते॥ सघानोयोगऽआभुवत्सरायेसपुरंध्यां
। गमद्वाजेभिरासनः॥ यस्यसंस्थेनवृण्वतेहरीसमत्सुशत्रवः। तस्माऽइंद्रायगायत॥ सुतपा
व्नेसुताऽइमेशुचयोयंतिवीतये। सोमासोदध्याशिरः॥ ९ ॥ त्वंसुतस्यपीतयेसद्योवृद्धोऽअ
जायथाः। इंद्रज्यैष्ठ्यायसुक्रतो॥ आत्वाविशंत्वाशवःसोमासऽइंद्रगिर्वणः। शंतेसंतुप्रचेतसे
॥ त्वांस्तोमाऽअवीवृधन्त्वामुक्थाशतक्रतो। त्वांवर्धंतुनोगिरः॥ अक्षितोतिःसनेदिमंवाजमिं
द्रःसहस्रिणं। यस्मिन्विश्वानिपौंस्या॥ मानोमर्ताऽअभिद्रुहन्तनूनामिंद्रगिर्वणः। ईशानोय

सं·प्र·१ वयावधं॥ १० ॥१०॥ युंजंति ब्रध्नमरुषं चरंतं परि तस्थुषः॥ रोचंते रोचना दिवि॥ युंजंत्यस्य काम्या
८ हरी विपक्षसा रथे॥ शोणा धृष्णू नृवाहसा॥ केतुं कृण्वन्नकेतवे पेशो मर्यो ऽअपेशसे॥ समुषद्भिर
जायथाः॥ आदह स्वधामनु पुनर्गर्भत्वमेरिरे॥ दधाना नाम यज्ञियं॥ वीळु चिदारुजत्नुभिर्गुहा
चिदिंद्र वह्निभिः॥ अविंद ऽउस्रिया ऽअनु॥ ११ ॥ देवयंतो यथा मतिमच्छा विदद्वसुं गिरः॥ मह
मनूषत श्रुतं॥ इंद्रेण सं हि दृक्षसे संजग्मानो ऽअबिभ्युषा॥ मंदू समानवर्चसा॥ अनवद्यैरभि
द्युभिर्मखः सहस्वदर्चति॥ गणैरिंद्रस्य काम्यैः॥ अतः परिज्मन्नागहि दिवो वा रोचनादधि॥
समस्मिन्नृंजते गिरः॥ इतो वा सातिमीमहे दिवो वा पार्थिवादधि॥ इंद्रं महो वा रजसः॥ १२ ॥१०
इंद्रमिद्गाथिनो बृहदिंद्रमर्केभिरर्किणः॥ इंद्रं वाणीरनूषत॥ इंद्र ऽइद्धर्योः सचा संमिश्ल ऽआव ८
चोयुजा॥ इंद्रो वज्री हिरण्ययः॥ इंद्रो दीर्घाय चक्षस ऽआ सूर्यं रोहयद्दिवि॥ वि गोभिरद्रिमैरयत॥

इंद्रवाजेषुनोव सुहस्त्रप्रधनेषुच॥उग्रऽउग्राभिरूतिभिः॥इंद्रंवयंमहाधनेऽइंद्रमर्भेहवामहे॥
युजंवृत्रेषुवज्रिणं॥ १२ ॥सनोवृषन्नमुंचरुंसत्रादावन्नपावृधि॥अस्मभ्यमप्रतिष्कुतः॥तुं
जेतुंजेयऽउत्तरेस्तोमाऽइंद्रस्यवज्रिणः॥नविंधेऽअस्यसुष्टुतिं॥वृषायूथेवंसगः कृष्टीरिय
र्त्योजसा॥ईशानोऽअप्रतिष्कुतः॥यऽएकश्चर्षणीनांवसूनामिरज्यति॥इंद्रः पंचक्षितीनां॥इं
द्रंवोविश्वतस्परिहवामहेजनेभ्यः॥अस्माकमस्तुकेवलः॥ १४ ॥१० अनुवाकः॥ २ एंद्रसा
नसिंरयिंसजित्वानंसदासहं॥वर्षिष्ठमूतयेभर॥नियेनमुष्टिहत्ययानिवृत्रारुणधामहै॥त्वोता
सोन्यर्वता॥इंद्रत्वोतासऽआवयंवज्रंघनाददीमहि॥जयेमसंयुधिस्पृधः॥वयंशूरेभिरस्तृभि
रिंद्रत्वयायुजावयं॥सासह्यामपृतन्यतः॥महाँऽइंद्रः परश्चनुमहित्वमस्तुवज्रिणे॥द्यौर्नप्र
थिनाशवः॥ १५ ॥समोहेवायऽआशतनरस्तोकस्यसनितौ॥विप्रासोवाधियायवः॥यःकु

सं॰प्र॰१ क्षिः सोमपातमः समुद्रऽइव पिन्वते। उर्वीरापो न काकुदः॥ एवा ह्यस्य सूनृता विरप्शी गोमती मु
९ ही। पक्वा शाखा न दाशुषे॥ एवा हि ते विभूतय ऊतय इन्द्र मावते। सद्यश्चित्संति दाशुषे॥ एवा
ह्यस्य काम्या स्तोमऽउक्थं च शंस्या। इंद्राय सोमपीतये॥ १६ ॥ १० इंद्रेहि मत्स्यंधसो विश्वेभिः
सोमपर्वभिः। महाँ अभिष्टिरोजसा॥ एमेनं सृजता सुते मंदिमिंद्राय मंदिने। चक्रिं विश्वानि चक्र
ये॥ मत्स्वा सुशिप्र मंदिभिः स्तोमेभिर्विश्वचर्षणे। सचेषु सवनेष्वा॥ असृग्रमिंद्र ते गिरः प्रति त्वा
मुदहासत। अजोषा वृषभं पतिं॥ संचोदय चित्रमर्वाग्राधऽइंद्र वरेण्यं। असदित्ते विभु प्रभु॥
॥ १७ ॥ अस्मान्त्सु तत्र चोदयेंद्र राये रभस्वतः। तुविद्युम्न यशस्वतः॥ सं गोमदिंद्र वाजवदस्मे
पृथु श्रवो बृहत्। विश्वायुर्धेह्यक्षितं॥ अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमं। इंद्र ता रथि
नीरिषः॥ वसोरिंद्रं वसुपतिं गीर्भिर्गृणंतऽऋग्मियं। होम गंतारमूतये॥ सुतेसुते न्योकसे बृहद्बृह

हृतऽएद्रिः॥इंद्रायशूषमर्चति॥ १८ ॥१० गायंतित्वागायत्रिणोऽर्चंत्यर्कमर्किणः॥ब्रह्माणस्त्वाश
तक्रतऽउद्वंशमिवयेमिरे॥यत्सानोःसानुमारुहद्भूर्यस्पष्टकर्त्वं॥तदिंद्रोऽअर्थंचेततियूथेनवृष्णि
रेजति॥युक्ष्वाहिकेशिनाहरीवृषणाकक्ष्यप्रा॥अथानऽइंद्रसोमपागिरामुपश्रुतिंचर॥एहिस्तो
माँऽअभिस्वराभिगृणीह्यारुव॥ब्रह्मचनोवसोसचेंद्रयज्ञंचवर्द्धय॥उक्थमिंद्रायशंस्यंवर्धनंपु
रुनिःषिधे॥शक्रोयथासुतेषुणोरारणत्सख्येषुच॥तमित्सखित्वऽईमहेतंरायेतंसुवीर्ये॥सशक्र
ऽउतनःशकदिंद्रोवसुदयमानः॥ १९ ॥सुविवृतंसुनिरजमिंद्रत्वादातमिद्यशः॥गवामपव्रजं
वृधिकृणुष्वराधोऽअद्रिवः॥नहित्वारोदसीऽउभेऽऋघायमाणमिन्वतः॥जेषःस्वर्वतीरपःसं
गाऽअस्मभ्यंधूनुहि॥आश्रुत्कर्णश्रुधीहवंनूचिद्दधिष्वमेगिरः॥इंद्रस्तोममिमंममकृष्वायुज
श्चिदंतरं॥विद्माहित्वावृषंतमंवाजेषुहवनश्रुतं॥वृषंतमस्यहूमहऽऊतिंसहस्रसातमां॥आ

सं॰प्र॰१ ह्वनऽइंद्रकौशिकमंदसानः सुतंपिब। नव्यमायुःप्रसूतिरकृधीसहस्रसामृषिं॥ परित्वागिर्वणोगि
१० रऽइमाभवंतुविश्वतः। वृद्धायुमनुवृद्धयोजुष्टाभवंतुजुष्टयः॥ २० ॥ १२ इंद्रंविश्वाऽअवीवृध
न्त्समुद्रव्यचसंगिरः। रथीतमंरथीनांवाजानांसत्पतिंपतिं॥ सख्येतऽइंद्रवाजिनोमाभेमशव
सस्पते। त्वामभिप्रणोनुमोजेतारमपराजितं॥ पूर्वीरिंद्रस्यरातयोनविदस्यंत्यूतयः॥ यदीवाजं
स्यगोमतःस्तोतृभ्योमंहतेमघं॥ पुरांभिंदुर्युवाकविरमितौजाऽअजायत। इंद्रोविश्वस्यकर्मणो
धर्तावज्रीपुरुष्टुतः॥ त्वंवलस्यगोमतोपावरद्रिवोबिलं॥ त्वांदेवाऽअबिभ्युषस्तुज्यमानासऽआ
विषुः॥ तवाहंशूररातिभिःप्रत्यायंसिंधुमावदन्। उपातिष्ठंतगिर्वणोविदुष्टेतस्यकारवः॥ माया
भिरिंद्रमायिनंत्वंशुष्णमवातिरः। विदुष्टेतस्यमेधिरास्तेषांश्रवांस्युत्तिर॥ इंद्रमीशानमोजसा १०
ऽभिस्तोमाऽअनूषत। सहस्रंयस्यरातयऽउतवासंतिभूयसीः॥ २१ ॥ ८ अनुवाकः॥ ३ ॥

अग्निं दूतं वृणीमहे होतारं विश्ववेदसं। अस्य यज्ञस्य सुक्रतु॥ अग्निमग्निं हवीमभिः सदा हवंत वि
श्पतिं। हव्यवाहं पुरुप्रियं॥ अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे। असि होता न ईड्यः॥ ताँ
उशतो वि बोधय यदग्ने यासि दूत्यं। देवैरा सत्सि बर्हिषि॥ घृताहवन दीदिवः प्रति ष्म रिषतो दह।
अग्ने त्वं रक्षस्विनः॥ अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा। हव्यवाड्जुह्वास्यः॥ २२ ॥ कविम
ग्निमुप स्तुहि सत्यधर्माणमध्वरे। देवममीवचातनं॥ यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति। तस्य
स्म प्राविता भव॥ योऽअग्निं देववीतये हविष्माँ आविवासति। तस्मै पावक मृळय॥ स नः पावक दी
दिवोऽग्ने देवाँ इहा वह। उप यज्ञं हविश्च नः॥ स नः स्तवान आ भर गायत्रेण नवीयसा। रयिं वी
रवतीमिषं॥ अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः। इमं स्तोमं जुषस्व नः॥ २३ ॥ १२ सुसमि
द्धो नऽआ वह देवाँ अग्ने हविष्मते। होतः पावक यक्षि च॥ मधुमंतं तनूनपाद्यज्ञं देवेषु नः कवे।

सं·प्र·१ अद्या कृणुहि वीतये॥ नराशंसमिह प्रियमस्मिन्यज्ञऽउपह्वये॥ मधुजिह्वं हविष्कृतं॥ अग्ने सुखतमे
११ रथे देवाँ ईळितऽआवह॥ असि होता मनुर्हितः॥ स्तृणीत बर्हिरानुषग्घृतपृष्ठं मनीषिणः॥ यत्रामृ
तस्य चक्षणं॥ विश्रयंतामृतावृधो द्वारो देवीरसश्चतः॥ अद्या नूनं च यष्टवे॥ २४ ॥ नक्तोषासा सु
पेशसाऽस्मिन्यज्ञऽउपह्वये॥ इदं नो बर्हिरासदे॥ ता सुजिह्वाऽउपह्वये होतारा दैव्या कवी॥ यज्ञं
नो यक्षतामिमं॥ इळा सरस्वती मही तिस्रो देवीर्मयोभुवः॥ बर्हिः सीदंत्वस्रिधः॥ इह त्वष्टारमग्रि
१४ यं विश्वरूपमुपह्वये॥ अस्माकमस्तु केवलः॥ अव सृजा वनस्पते देव देवेभ्यो हविः॥ प्र दातुरस्तु
चेतनं॥ स्वाहा यज्ञं कृणोतनेंद्राय यज्वनो गृहे॥ तत्र देवाँ उपह्वये॥ २५ ॥ १२ ऐभिरग्ने दुवो गि
रो विश्वेभिः सोमपीतये॥ देवेभिर्याहि यक्षि च॥ आ त्वा कण्वाऽअहूषत गृणंति विप्र ते धियः॥ ११
देवेभिरग्नऽआगहि॥ इंद्रवायू बृहस्पतिं मित्राग्निं पूषणं भगं॥ आदित्यान्मारुतं गणं॥ प्र वो भ्रि

यंतऽइंद्रवो मत्सरा मादयिष्णवः॥ द्रप्सा मध्वश्चमूषदः॥ ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः॥ हविष्मंतोऽअरंकृतः॥ घृतपृष्ठा मनोयुजो ये त्वा वहंति वह्नयः॥ आदेवान्त्सोमपीतये॥ २६ ॥ तान्यजत्राँऽऋतावृधोऽग्ने पत्नीवतस्कृधि॥ मध्वः सुजिह्व पायय॥ ये यजत्रा यऽईड्यास्ते ते पिबंतु जिह्वया॥ मधोरग्ने वषट्कृति॥ आकीं सूर्यस्य रोचनाद्विश्वान्देवाँऽउषर्बुधः॥ विप्रो होतेह वक्षति॥ विश्वेभिः सोम्यं मध्वग्नऽइंद्रेण वायुना॥ पिबा मित्रस्य धामभिः॥ त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि॥ सेमं नोऽअध्वरं यज॥ युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः॥ ताभिर्देवाँऽइहा वह॥ २७ ॥ १२ इंद्र सोमं पिबऽऋतुनाऽऽत्वा विशंत्विंदवः॥ मत्सरासस्तदोकसः॥ मरुतः पिबतऽऋतुना पोत्राद्यज्ञं पुनीतन॥ यूयं हि ष्ठा सुदानवः॥ अभि यज्ञं गृणीहि नोऽग्नावो नेष्टः पिबऽऋतुना॥ त्वं हि रत्नधाऽअसि॥

२२ अग्ने देवाँऽइहा वह सादया योनिषु त्रिषु॥ परि भूष पिबऽऋतुना॥ ब्राह्मणादिंद्र राधसः पिबा सो

सं·प्र·१ ममृतावृँ रतुना । तवेद्विसख्यमस्तृतं ॥ युवंदक्षंधृतव्रता मित्रावरुणदूळभं । ऋतुनायज्ञमाशाथे ॥ २८
१२ द्रविणोदाद्रविणसोग्रावहस्तासोऽअध्वरे । यज्ञेषुदेवमीळते ॥ द्रविणोदाददातुनोवसूनियानिशृ
ण्विरे । देवेषुतावनामहे ॥ द्रविणोदाःपिपीषतिजुहोतप्रचतिष्ठत । नेष्ट्राहृतुभिरिष्यत ॥ यन्त्वातुरी
यमृतुभिर्द्रविणोदोयजामहे । अधस्मानोददिर्भव ॥ अश्विनापिबतंमधुदीद्यग्नीशुचिव्रता । ऋ
तुनायज्ञवाहसा ॥ गार्हपत्येनसंत्यऽऋतुनायज्ञनीरसि । देवान्देवयतेयज ॥ २९ ॥ १२ आत्वा
वहंतुहरयोवृषणंसोमपीतये । इंद्रत्वासूरचक्षसः ॥ इमाधानाघृतस्नुवोहरीऽइहोपवक्षतः । इंद्रं
सुखतमेरथे ॥ इंद्रंप्रातर्हवामहऽइंद्रंप्रयत्यध्वरे । इंद्रंसोमस्यपीतये ॥ उपनःसुतमागहिहरि
भिरिंद्रकेशिभिः ॥ सुतेहित्वाहवामहे ॥ सेमंनःस्तोममागह्युपेदंसवनंसुतं । गौरोनतृषितःपिब १२
॥ ३० ॥ इमेसोमासऽइंदवःसुतासोऽअधिबर्हिषि । ताँऽइंद्रसहसेपिब ॥ अयंतेस्तोमोऽअग्रि

यो हृदिस्पृगस्तु शंतमः । अथा सोमं सुतं पिब ।। विश्वमित्सवनं सुतमिंद्रो मदाय गच्छति । वृत्रहा सो
३० मपीतये ।। सेमं नः काममापृण गोभिरश्वैः शतक्रतो । स्तवाम त्वा स्वाध्यः ।। ३१ ।। १ इंद्रावरुण
योरहं सम्राजोरव ऽ आवृणे । ता नो मृळात ऽ ईदृशे ।। गंतारा हि स्थोवसे हवं विप्रस्य मावतः । धर्तारा
चर्षणीनां ।। अनुकामं तर्पयेथामिंद्रावरुण राय ऽ आ । ता वां नेदिष्ठमीमहे ।। युवाकु हि शचीनां युवा
कु सुमतीनां । भूयाम वाजदाव्नां ।। इंद्रः सहस्रदाव्नां वरुणः शंस्यानां । क्रतुर्भवत्युक्थ्यः ।। ३२ ।। तयो
रिदवसा वयं सनेम नि च धीमहि । स्यादुत प्ररेचनं ।। इंद्रावरुण वामहं हुवे चित्राय राधसे । अस्मा
न्सुजिग्युषस्कृतं ।। इंद्रावरुण नू नु वां सिषासंतीषु धीष्वा । अस्मभ्यं शर्म यच्छतं ।। प्र वामश्नोतु
सुष्टुतिरिंद्रावरुण यां हुवे । यामृधाथे सधस्तुतिं ।। ३३ ।। १ अनुवाकः ।। ४ सोमानं स्वरणं कृ
णुहि ब्रह्मणस्पते । कक्षीवंतं य ऽ औशिजः ।। यो रेवान्यो ऽ अमीवहा वसुवित्पुष्टिवर्धनः ।। स नः सि

सं॰प्र॰१ षक्रुयस्तुरः॥मानःशंसोऽअररुषोधूर्तिःप्रणङ्मर्त्यस्य॥रक्षाणोब्रह्मणस्पते॥सघावीरोनरिष्य
१३ तियमिंद्रोब्रह्मणस्पतिः॥सोमोहिनोतिमर्त्यं॥त्वंतंब्रह्मणस्पतेसोमऽइंद्रश्चमर्त्यं॥दक्षिणापा
त्वंहसः॥ ३४ ॥सदसस्पतिमद्भुतंप्रियमिंद्रस्यकाम्यं॥सनिंमेधामयासिषं॥यस्मादृतेनसिध्य
तियज्ञोविपश्चितश्चन॥सधीनांयोगमिन्वति॥आदृध्नोतिहविष्कृतिंप्रांचंकृणोत्यध्वरं॥होत्रा
देवेषुगच्छति॥नराशंसंसुधृष्टममपश्यंसप्रथस्तमं॥दिवोनसद्ममखसं॥ ३५ ॥ १ प्रतित्यं
चारुमध्वरंगोपीथायप्रहूयसे॥मरुद्भिरग्नऽआगहि॥नहिदेवोनमर्त्योमहस्तवक्रतुंपरः॥म
रुद्भि०॥येमहोरजसोविदुर्विश्वेदेवासोऽअद्रुहः॥मरुद्भि०॥येऽउग्राऽअर्कमानृचुरनाधृष्टा
सऽओजसा॥मरुद्भि०॥येशुभ्राघोरवर्पसःसुक्षत्रासोरिशादसः॥मरुद्भि०॥ ३६ ॥येनाकस्या १३
धिरोचनेदिविदेवासआसते॥मरुद्भि०॥यईंखयंतिपर्वतान्तिरःसमुद्रमर्णवं॥मरुद्भि०॥

आयेतन्वंतिरश्मिभिस्तिरःसमुद्रमोजसा॥मरुद्भिः॥अभित्वापूर्वपीतयेसृजामिसोम्यंमधु॥
मरुद्भिः॥ ३७ ॥ १।१९।१९४ ॥ ये।नाकस्य।अधि।रोचने।दिवि।देवासः।आसते।०।ये।
ईंखयंति।पर्वतान्।तिरः।समुद्रं।अर्णवं।०।आ।ये।तन्वंति।रश्मिऽभिः।तिरः।समुद्रं।ओजसा
।०।अभि।त्वा।पूर्वऽपीतये।सृजामि।सोम्यं।मधु।०॥ ३७ ॥इतिसंहिताप्रथमाष्टकेप्रथमो
ध्यायः॥ ॥ ॐ ॥अयमष्टावाभर्वमिहषळैंद्राग्नेश्रातयुंजासैकाचतस्रआश्विन्यस्तथासा
के६ वित्र्यआग्नेय्योद्वेदेवीनामैकैंद्राणीवरुणान्यग्नायीनांद्यावापृथिव्येपार्थिवीषड्वैष्णव्योतोदेवा
देवीवातीत्राश्चतुर्विंशतिर्वायव्येकैंद्रवायव्यौमैत्रावरुणमरुत्वतीयवैश्वदेवपौष्णास्तृचाःशि
ष्टाआप्योत्याध्यर्द्धाग्नेय्यस्त्वंतःपुरउष्णिक्परानुष्टुप्तिस्रश्चांत्याएकविंशीप्रतिष्ठाकस्यपंचोना
ऽजीगर्तिःशुनःशेपःसकृत्रिमोवैश्वामित्रोदेवरातोवारुणंतुत्रैष्टुभंमाद्येकाग्न्याग्नेय्यौसावित्र

सं·प्र·२ स्तृचोगायत्रोस्योत्याभागीवायव्यश्चित्सेकावसिषदशाग्नेयंत्वश्वंसमोनागायत्रंस्यादैवीत्रिष्टुब्व्यत्र
१४ ग्रावाणनवषळनुष्टुबादित्यश्चिद्द्योलूखलस्यौपरेमौसलस्योचप्रजापतेर्हरिश्चंद्रस्यांत्याचर्मप्रशंसा
वायव्यश्चित्समपाद्रूमावोद्ध्युधिका ऽस्माकंपादनिवृच्छ्वत्रिष्टुप्परोतृचावाश्विनोषस्यौत्वमग्ने
द्यूनाहिरण्यस्तूपआग्नेयंत्रिष्टुबंस्याष्टमीषोळश्योचेंद्रस्यपंचोना॥ २ ॥ ॐ ॥अयंदेवाय
जन्मने'स्तोमोविप्रेभिरासया।अकारिरत्नधातमः॥यऽइंद्रायवचोयुजा'ततक्षुर्मनसाहरी।श
मीभिर्यज्ञमाशत॥तक्षन्नासत्याभ्यां'परिज्मानंसुखंरथं।तक्षन्धेनुंसबर्दुघां॥युवानापितरापु
नः'सत्यमंत्राऽऋजूयवः।ऋभवोविष्ट्यक्रत॥संवोमदासोऽअग्मतेंद्रेणचमरुत्वता।आदित्येभि
श्चराजभिः॥ १ ॥उतत्यंचमसंनवं'त्वष्टुर्देवस्यनिष्कृतं।अकर्तचतुरः पुनः॥तेनोरत्नानिधत्तन' १५
त्रिरासाप्तानिसुन्वते।एकमेकंसुशस्तिभिः॥अधारयंतवह्नयोऽभजंतसुकृत्यया।भागंदेवेषु

यज्ञियं॥ २ ॥ इंद्राग्नी ऽ उप ह्वये तयोरित्स्तोमं मुश्मसि। ता सोमं सोमपातमा॥ ता यज्ञेषु प्रशं
सतेंद्राग्नी शुंभता नरः। ता गायत्रेषु गायत॥ ता मित्रस्य प्रशस्तय ऽ इंद्राग्नी ता हवामहे। सोमपा सो
मपीतये॥ उग्रा संता हवामह ऽ उपेदं सवनं सुतं। इंद्राग्नी ऽ एह गच्छतां॥ ता महांता सदस्पती ऽ इं
द्राग्नी रक्ष ऽ उब्जतं। अप्रजाः संत्वत्रिणः॥ तेन सत्येन जागृतमधि प्रचेतुने पदे। इंद्राग्नी शर्म यच्छ
तं॥ ३ ॥ प्रातर्युजा विबोधयाश्विनावेह गच्छतां। अस्य सोमस्य पीतये॥ या सुरथा रथीतमोभा
देवा दिविस्पृशा। अश्विना ता हवामहे॥ या वां कशा मधुमत्यश्विना सूनृतावती। तया यज्ञं मिमिक्ष
तं॥ नहि वामस्ति दूरके यत्रा रथेन गच्छथः। अश्विना सोमिनो गृहं॥ हिरण्यपाणिमूतये सविता
रमुप ह्वये। स चेत्ता देवता पदं॥ ४ ॥ अपां नपातमवसे सवितारमुप स्तुहि। तस्य व्रतान्युश्मसि॥
विभक्तारं हवामहे वसोश्चित्रस्य राधसः। सवितारं नृचक्षसं॥ सखाय ऽ आ नि षीदत सविता स्तो

सं·प्र·२ म्योनुनः।दातुरा द्यौसिश्रुंमति॥अग्ने पत्नीरिहा वह'देवानामुशतीरूप।त्वष्टारंसोमपीतये॥
१५ आग्नाऽअग्नऽइहावसे'होत्रां यविष्ठभारतीं।वरूत्रीधिषणांवह॥ ५ ॥अभिनोदेवीरवसा'
महःशर्मणान्नृपत्नीः।अच्छिन्नपत्राःसचंतां॥इहेंद्राणीमुपह्वये'वरुणानींस्वस्तये।अग्नायीं
सोमपीतये॥महीद्यौःपृथिवीचनऽइमंयज्ञंमिमिक्षतां।पिपृतांनोभरीमभिः॥तयोरिद्घृतवत्पयो'
विप्रारिहंतिधीतिभिः।गंधर्वस्यध्रुवेपदे॥स्योनापृथिविभवा'नृक्षरानिवेशनी।यच्छानःशर्मस
प्रथः॥ ६ ॥अतोदेवाऽअवंतुनो'यतोविष्णुर्विचक्रमे।पृथिव्याःसप्तधामभिः॥इदंविष्णुर्विच
क्रमे'त्रेधानिदधेपदं।समूळ्हमस्यपांसुरे॥त्रीणिपदाविचक्रमे'विष्णुर्गोपाऽअदाभ्यः।अतो
धर्माणिधारयन्॥विष्णोःकर्माणिपश्यत'यतोव्रतानिपस्पशे।इंद्रस्ययुज्यःसखा॥तद्विष्णोः १५
परमंपदं'सदापश्यंतिसूरयः।दिवीवचक्षुराततं॥तद्विप्रासोविपन्यवो'जागृवांसःसमिंधते।

विष्णोर्यत्परमं पदं॥ ७ ॥ २१ तीव्राः सोमास ऽआ गह्याशीर्वंतः सुता ऽइमे। वायो तान्प्रस्थितान्पिब॥
४ उभा देवा दिविस्पृशेंद्रवायू हवामहे॥ अस्य सोमस्य पीतये॥ इंद्रवायू मनोजुवा' विप्रा हवंत ऽऊतये।
सहस्राक्षा धियस्पती॥ मित्रं वयं हवामहे' वरुणं सोमपीतये। जज्ञाना पूतदक्षसा॥ ऋतेन याव‍ृता
वृधावृतस्य ज्योतिषस्पती। ता मित्रावरुणा हुवे॥ ८ ॥ वरुणः प्राविता भुवं न्मित्रो विश्वाभिरूति
भिः। करतां नः सुराधसः॥ मरुत्वंतं हवामह ऽइंद्रमा सोमपीतये। सजूर्गणेन तृंपतु॥ इंद्रज्येष्ठा म
रुद्गणा' देवासः पूषरातयः। विश्वे मम श्रुता हवं॥ हत वृत्रं सुदानव ऽइंद्रेण सहसा युजा। मा नो दुः
शंस ऽईशत॥ विश्वान्देवान्हवामहे' मरुतः सोमपीतये। उग्रा हि पृश्निमातरः॥ ९ ॥ जयतामिव
तन्यतु'र्मरुतामेति धृष्णुया। यच्छुभं याथना नरः॥ हस्काराद्विद्युतस्प'र्यतो जाता ऽअवंतु नः।
मरुतो मृळयंतु नः॥ आ पूषञ्चित्रबर्हिष'माघृणे धरुणं दिवः। आजा नष्टं यथा पशुं॥ पूषा रा

सं·अ·२ जानमाघृणि'रपगूळ्हंगुहाहितं।अविंदच्चित्रबर्हिषं॥उतोसमह्यमिंदुभिःषड्युक्ताँऽअनु
१६ सेषिधत।गोभिर्यवंनचर्कृषत॥ १० ॥अंबयोयंत्यध्वभिर्जामयोऽअध्वरीयतां।पृंचती
र्मधुनापयः॥अमूर्याऽउपसूर्ये'याभिर्वासूर्यःसह।तानोहिन्वंत्वध्वरं॥अपोदेवीरुपह्वये'
यत्रगावःपिबंतिनः।सिंधुभ्यःकर्त्वंहविः॥अप्स्वं१तरमृतमप्सुभेषजं'मपामुतप्रशस्तये।दे
वाभवतवाजिनः॥अप्सुमेसोमोऽअब्रवीदंतर्विश्वानिभेषजा।अग्निंचविश्वशंभुव'माप
श्चविश्वभेषजीः॥ ११ ॥आपःपृणीतभेषजं'वरूथंतन्वे३मम।ज्योक्चसूर्यंदृशे॥इदमापः
प्रवहत'यत्किंचदुरितंमयि।यद्वाहमभिदुद्रोह'यद्वाशेपऽउतानृतं॥आपोऽअद्यान्वचारि
षं'रसेनसमगस्महि।पयस्वानग्नऽआगहि'तंमासंसृजवर्चसा॥संमाग्नेवर्चसासृज'सं १६
प्रजयासमायुषा।विद्युर्मेऽअस्यदेवाऽइंद्रोविद्यात्सहऽऋषिभिः॥ १२ ॥२४ अनुवाकः॥

५ कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम । को नो मह्याऽअदितये पुनर्दात् पितरं च दृ
शेयं मातरं च ॥ अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम । स नो मह्याऽअदितये पुनर्दात्
पितरं च दृशेयं मातरं च ॥ अभि त्वा देव सवितरीशानं वार्याणां । सदावन्भागमीमहे ॥ यश्चिद्धि तऽइत्था
भगः शशमानः पुरा निदः । अद्वेषो हस्तयोर्दधे ॥ भगभक्तस्य ते वयमुदशेम तवावसा । मूर्धानं रायऽ
आरभे ॥ १३ ॥ नहि ते क्षत्रं न सहो न मन्युं वयश्चनामी पतयंतऽआपुः । नेमाऽआपोऽअनिमिषं
चरंतीर्न ये वातस्य प्रमिनंत्यभ्वं ॥ अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः । नीचीनाः स्थु
रुपरि बुध्नऽएषामस्मेऽअंतर्निहिताः केतवः स्युः ॥ उरुं हि राजा वरुणश्चकार सूर्याय पंथामन्वेत
वाऽउ । अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित् ॥ शतं ते राजन्भिषजः सहस्रमु
र्वी गभीरा सुमतिष्टेऽअस्तु । बाधस्व दूरे निर्ऋतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत् ॥ अमी यऽऋ

सं·प्र·२ क्षत्रानिहितासऽउच्चा नक्तंददृश्रेकुहचिद्दिवेयुः।अदब्धानिवरुणस्यव्रतानिविचाकशच्चंद्रमा
१७ नक्तमेति॥ १४ ॥तत्त्वायामिब्रह्मणावंदमानस्तदाशास्तेयजमानोहविर्भिः।अहेळमानोवरुणे
हबोध्युरुशंसमानऽआयुःप्रमोषीः॥तदिन्नक्तंतद्दिवामह्यमाहुस्तदयंकेतोहृदऽआविचष्टे।
शुनःशेपोयमह्वद्गृभीतःसोऽअस्मान्राजावरुणोमुमोक्तु॥शुनःशेपोह्यह्वद्गृभीतस्त्रिष्वादि
त्यंद्रुपदेषुबद्धः।अवैनंराजावरुणःससृज्याद्विद्वाँऽअदब्धोविमुमोक्तुपाशान्॥अवतेहेळोव
रुणनमोभिरवयज्ञेभिरीमहेहविर्भिः।क्षयन्नस्मभ्यमसुरप्रचेताराजन्नेनांसिशिश्रथःकृतानि॥
उदुत्तमंवरुणपाशमस्मदवाधमंविमध्यमंश्रथाय।अथावयमादित्यव्रतेतवानागसोऽअदितये
स्याम॥ १५ ॥ १ यच्चिद्धितेविशोयथाप्रदेववरुणव्रतं।मिनीमसिद्यविद्यवि॥मानोवधायहत्नवे १७
जिहीळानस्यरीरधः।माहृणानस्यमन्यवे॥विमृळीकायतेमनोरथीरश्वंनसंदितं।गीर्भिर्वरुणसी

महि॥ परा हि मे विमन्यवः पतन्ति वस्यऽइष्टये। वयो न वसतीरुप॥ कदा क्षत्रश्रियं नरमा वरुणं कराम
हे। मृळीकायोरुचक्षसं॥ १६ ॥ तदित्समानमाशाते वेनन्ता न प्रयुच्छतः। धृतव्रताय दाशुषे॥ वेदा
यो वीनां पदमन्तरिक्षेण पततां। वेद नावः समुद्रियः॥ वेद मासो धृतव्रतो द्वादश प्रजावतः। वेदा यऽ
उपजायते॥ वेद वातस्य वर्तनिमुरोर्ऋष्वस्य बृहतः। वेदा येऽअध्यासते॥ नि षसाद धृतव्रतो वरुणः
पस्त्याऽस्वा। साम्राज्याय सुक्रतुः॥ १७ ॥ अतो विश्वान्यद्भुता चिकित्वाँऽअभि पश्यति। कृतानि
या च कर्त्वा॥ स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत्। प्रणऽआयूंषि तारिषत्॥ बिभ्रद्द्रापिं हिर
ण्ययं वरुणो वस्त निर्णिजं। परि स्पशो नि षेदिरे॥ न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानां। न देव
मभिमातयः॥ उत यो मानुषेष्वा यशश्चक्रेऽअसाम्या। अस्माकमुदरेष्वा॥ १८ ॥ परा मे यन्ति धी
तयो गावो न गव्यूतीरनु। इच्छन्तीरुरुचक्षसं॥ सं नु वोचावहै पुनर्यतो मे मध्वाभृतं। होतेव क्षद

सं॰प्र॰२ से प्रियं॥ दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि। एता जुषत मे गिरः॥ इमं मे वरुण श्रुधी हवमद्या च
१८ मृळय। त्वामवस्युरा चके॥ त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि। स यामनि प्रति श्रुधि॥ उदु
त्तमं मुमुग्धि नो वि पाशं मध्यमं चृत। अवाधमानि जीवसे॥ १९ ॥ २१ वसिष्वा हि मियेध्य व
१।२७ स्त्राण्यूर्जां पते। सेमं नो ऽअध्वरं यज॥ नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः। अग्ने दिवित्मता
वचः॥ आ हि ष्मा सूनवे पिता ऽऽपिर्यजत्यापये। सखा सख्ये वरेण्यः॥ आ नो बर्ही रिशादसो वरुणो
मित्रो ऽअर्यमा। सीदंतु मनुषो यथा॥ पूर्व्य होतरस्य नो मंदस्व सख्यस्य च। इमा ऽउ षु श्रुधी गिरः
१६ ॥ २० ॥ यच्चिद्धि शश्वता तना देवंदेवं यजामहे। त्वे ऽइद्धूयते हविः॥ प्रियो नो ऽअस्तु विश्पतिर्हो
ता मंद्रो वरेण्यः। प्रियाः स्वग्नयो वयं॥ स्वग्नयो हि वार्यं देवासो दधिरे च नः। स्वग्नयो मनामहे॥ १८
अथा न ऽउभयेषाममृत मर्त्यानां। मिथः संतु प्रशस्तयः॥ विश्वेभिरग्ने ऽअग्निभिरिमं यज्ञमि

दं॑ वचः॑। चनो॑ धाः सहसो यहो॥ २१॥ अश्वं॒ न त्वा॒ वार॑वंतं व॒ंदध्या॑ऽअ॒ग्निं नमो॑भिः। स॒म्राजं॑तम
ध्व॒राणा॑म्॥ स घा॑ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेवः॑। मी॒ढ्वाँ अ॒स्माकं॑ बभूयात्॥ सनो॑ दू॒राच्चा॒साच्च॒ नि
मर्त्या॑दघा॒योः। पा॒हि सद॒मिद्वि॒श्वायुः॑॥ इ॒मम्ू षु त्वम॒स्माकं॑ स॒निं गा॑य॒त्रं नव्यां॑सं। अग्ने॑ दे॒वेषु॒ प्र वो॑चः
॥ आ नो॑ भज पर॒मे॑ष्वा वाजे॑षु मध्य॒मेषु॑। शिक्षा॒ वस्वो॒ऽअंत॑मस्य॥ २२ ॥ विभ॒क्तासि॑ चित्रभानो॒ सिंधो॑
रू॒र्मा॑ऽउपा॒कऽआ। स॒द्यो दा॒शुषे॑ क्षरसि॥ यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु यं जु॒नाः। स यंता॒ शश्व॑तीरि
षः॥ नकि॑रस्य सहंत्य पर्ये॒ता कय॑स्य चित्। वाजो॑ऽअस्ति श्र॒वाय्यः॑॥ स वाजं॑ विश्वच॑र्षणि॒रर्वद्भि॑रस्तु
तरु॒ता। विप्रे॑भिरस्तु॒ सनि॑ता॥ जरा॑बोध॒ तद्वि॑विड्ढि वि॒शेवि॑शे य॒ज्ञियाय। स्तोमं॑ रु॒द्राय॑ दृ॒शीकं॑॥ २३
सनो॑ म॒हाँ अ॑निमा॒नो धू॒मके॑तुः पुरु॒श्चं॒द्रः। धि॒ये वाजा॑य हिन्वतु॥ स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्यः॑ के॒तुः
शृ॒णोतु नः। उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः॥ नमो॑ म॒हद्भ्यो॒ नमो॑ऽअर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ऽआशि॒नेभ्यः॑।

सं·प्र·२ यजामदेवान्यदिशक्नवामु'माज्यायसःशंसमावृक्षिदेवाः॥ २४ ॥ १३ यत्रग्रावापृथुबुध्नऽ'ऊर्ध्वोभ
१९ वतिसोतवे।उलूखलसुतानां'मवेदिंद्रजल्गुलः॥यत्रद्वाविवजघनाऽ'धिषवण्याकृता।उलूखल
सुतानां०॥यत्रनार्यपच्यवंमुपच्यवंचशिक्षते।उलूखल०॥यत्रमंथांविबध्नते'रश्मीन्यमितवाऽ
इव।उलूखल०॥यच्चिद्धित्वंगृहेगृहऽउलूखलकयुज्यसे।इहद्युमत्तमंवद'जयतामिवदुंदुभिः॥
॥ २५ ॥उतस्मतेवनस्पते'वातोविवात्यग्रमित्।अथोऽइंद्रायपातवे'सुनुसोममुलूखल॥आयु
जीवाजसातमा'ताह्युच्चाविजर्भृतः।हरीऽइवांधांसिबप्सता॥तानोऽअद्यवनस्पतीऽऋष्वावृष्वे
भिःसोतृभिः।इंद्रायमधुमत्सुतं॥उच्छिष्टंचम्वोर्भर'सोमंपवित्रऽआसृज।निधेहिगोरधित्वचि
१६ ॥ २६ ॥ यच्चिद्धिसत्यसोमपाऽ'अनाशस्ताऽइवस्मसि।आतूनऽइंद्रशंसय'गोष्वश्वेषुशु १९
भ्रिषु'सहस्रेषुतुवीमघ॥शिप्रिन्वाजानांपते'शचीवस्तवदंसना।आतूनऽइंद्र०॥निधापयामिथू

१२१

दृशा'सस्तामबुध्यमाने। आ तू न०॥ ससंतु त्या ऽअरातयो' बोधंतु शूर रातयः॥ आ तू न०॥ समिंद्र ग
र्दभं मृण'नुवंतं पापयामुया। आ तू न०॥ पताति कुंडृणाच्या' दूरं वातो वनादधि। आ तू न०॥ सर्वं प
रिक्रोशं जहि' जंभया कृकदाश्वं। आ तू न०॥ २७ ॥ ७ आ व इंद्रं क्रिविं यथा' वाजयंतः शतक्रतुं।
मंहिष्ठं सिंच ऽइंदुभिः॥ शतं वा यः शुचीनां' सहस्रं वा समाशिरां। एदु निम्नं न रीयते॥ सं यन्मदाय शु
ष्मिणे ऽएना ह्यस्योदरे। समुद्रो न व्यचो दधे॥ अयमु ते समतसि' कपोत ऽइव गर्भधिं। वचस्तच्चिन्न ऽ
ओहसे॥ स्तोत्रं राधानां पते' गिर्वाहो वीर यस्य ते। विभूतिरस्तु सूनृता॥ २८ ॥ ऊर्ध्वस्तिष्ठा न ऽऊत
ये' ऽस्मिन्वाजे शतक्रतो। समन्येषु ब्रवावहै॥ योगेयोगे तवस्तरं' वाजेवाजे हवामहे। सखाय ऽइंद्र
मूतये॥ आ घा गमद्यदि श्रवत्' सहस्रिणीभिरूतिभिः। वाजेभिरुप नो हवं॥ अनु प्रत्नस्यौकसो' हु
वे तुविप्रतिं नरं। यं ते पूर्वं पिता हुवे॥ तं त्वा वयं विश्ववारा' शास्महे पुरुहूत। सखे वसो जरितृभ्यः॥ २९

सं॰ अ॰ २ अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नां। सखे वज्रिन्त्सखीनां॥ तथा तदस्तु सोमपाः सखे वज्रिन्तथा
२० कृणु। यथा तऽउश्मसीष्टये॥ रेवतीर्नः सधमादऽइंद्रे संतु तुविवाजाः। क्षुमंतो याभिर्मदेम॥ आ घ
त्वावान्त्मनाप्तः स्तोतृभ्यो धृष्णवियानः। ऋणोरक्षं न चक्र्योः॥ आ यद्दुवः शतक्रतवा कामं जरितॄ
णां। ऋणोरक्षं न शचीभिः॥ ३० ॥ शश्वदिंद्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि। स नो
हिरण्यरथं दंसनावान्त्स नः सनिता सनये स नोऽदात्॥ आश्विनावश्वावत्येषा यातं शवीरया। गोम
द्दस्रा हिरण्यवत्॥ समानयोजनो हि वां रथो दस्रावमर्त्यः। समुद्रेऽअश्विनेयते॥ न्य१घ्न्यस्य मूर्ध
नि चक्रं रथस्य येमथुः। परि द्यामन्यदीयते॥ कस्तऽउषः कधप्रिये भुजे मर्तोऽअमर्त्ये। कं नक्षसे
विभावरि॥ वयं हि तेऽअमन्मह्यांतादा पराकात्। अश्वे न चित्रेऽअरुषि॥ त्वं त्येभिरा गहि वाजेभि २०
र्दुहितर्दिवः। अस्मे रयिं नि धारय॥ ३१ ॥२२ अनुवाकः॥६ त्वमग्ने प्रथमोऽअंगिराऽऋषिर्दे

वोदेवानामभवः शिवः सखा। तवव्रतेकवयोविद्मनापसोऽजायंतमरुतोभ्राजदृष्टयः॥ त्वमग्नेप्रथमो
ऽअंगिरस्तमः कविर्देवानांपरिभूषसिव्रतं। विभुर्विश्वस्मैभुवनायमेधिरो द्विमाताशयुः कतिधाचि
दायवे॥ त्वमग्नेप्रथमोमातरिश्वनेऽआविर्भवसुक्रतूयाविवस्वते। अरेजेतांरोदसीहोतृवूर्ये स
घ्नोर्भारमयजोमहोवसो॥ त्वमग्नेमनवेद्यामवाशयः पुरूरवसेसुकृतेसुकृत्तरः। श्वात्रेणयत्पित्रो
र्मुच्यसेपर्यात्वापूर्वमनयन्नापरंपुनः॥ त्वमग्नेवृषभःपुष्टिवर्धनऽउद्यतस्रुचेभवसिश्रवाय्यः।
यऽआहुतिंपरिवेदावषट्कृतिमेकायुरग्रेविशऽआविवाससि॥ ३२ ॥ त्वमग्नेवृजिनवर्तनिंन
रं सक्मन्पिपर्षिविदथेविचर्षणे। यःशूरसातापरितक्म्येधनेदभ्रेभिश्चित्समृताहंसिभूयसः॥
त्वंतमग्नेऽअमृतत्वऽउत्तमेमर्तंदधासिश्रवसेदिवेदिवे। यस्तातृषाणऽउभयायजन्मनेमयः
कृणोषिप्रयऽआचसूरये॥ त्वंनोऽअग्नेसनयेधनानांयशसंकारुंकृणुहिस्तवानः। ऋध्यामक

सं॰प्र॰२ र्मोपस्थानवेन'देवैद्यौर्वापृथिवीप्रावतंनः॥त्वंनोऽअग्नेपित्रोरुपस्थेऽआ'देवोदेवेष्वनवद्यजागृ
२१ विः॥तनूकृद्बोधिप्रमतिश्चकारवे'त्वंकल्याणवसुविश्वमोपिषे॥त्वमग्नेप्रमतिस्त्वंपितासिनस्त्वं
वयस्कृत्तवजामयोवयं॥संत्वारायःशतिनःसंसहस्रिणःसुवीरंयंतिव्रतपामदाभ्य॥ ३२ ॥त्वा
मग्नेप्रथममायुमायवे'देवाऽअकृण्वन्नहुषस्यविश्पतिं॥इळामकृण्वन्मनुषस्यशासनीं'पितु
र्यत्पुत्रोममकस्यजायते॥त्वंनोऽअग्नेतवदेवपायुभिर्मघोनोरक्षतन्वश्चवंद्य॥त्रातातोकस्यत
नयेगवामस्यनिमेषंरक्षमाणस्तवव्रते॥त्वमग्नेयज्यवेपायुरंतरो'निषंगायचतुरक्षऽइध्यसे
॥योरातहव्योवृकायधायसे'कीरेश्चिन्मंत्रंमनसावनोषितं॥त्वमग्नऽउरुशंसायवाघते'स्पार्हं
यद्रेक्णःपरमंवनोषितत्॥आध्रस्यचित्प्रमतिरुच्यसेपिता'प्रपाकंशास्सिप्रदिशोविदुष्टरः॥ २१
त्वमग्नेप्रयतदक्षिणंनरं'वर्मेवस्यूतंपरिपासिविश्वतः॥स्वादुक्षद्मायोवसतौस्योनकृ'ज्जीवयाजं

यजंति सोप्रमा दिवः॥ ३४॥ इमामग्ने शरणिं मीमृषो नऽइममध्वानं यमगाम दूरात्। आपिः पिता प्रमतिः
सोम्यानां भृमिरस्यृषिकृन्मर्त्यानां॥ मनुष्वदग्नेऽअंगिरस्वदंगिरो ययातिवत्सदने पूर्ववच्छुचे। अ
च्छ याह्या वहा दैव्यं जनमासादय बर्हिषि यक्षि च प्रियं॥ एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते
चकृमा विदा वा। उत प्रणेष्यभि वस्योऽअस्मान्त्सं नः सृज सुमत्या वाजवत्या॥ ३५॥ १ इंद्रस्य नु वी
र्याणि प्र वोचं यानि चकार प्रथमानि वज्री। अहन्नहिमन्वपस्ततर्द प्र वक्षणाऽअभिनत्पर्वतानां॥
अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष। वाश्राऽइव धेनवः स्यंदमानाऽअंजः समु
द्रमव जग्मुरापः॥ वृषायमाणो वृणीत सोमं त्रिकद्रुकेष्वपिबत्सुतस्य। आ सायकं मघवादत्त वज्रम
हन्नेनं प्रथमजामहीनां॥ यदिंद्राहन्प्रथमजामहीनामान्मायिनाममिनाः प्रोत मायाः। आत्सूर्यं
जनयन्द्यामुषासं तादीत्ना शत्रुं न किला विवित्से॥ अहन्वृत्रं वृत्रतरं व्यंसमिंद्रो वज्रेण महता व

सं·अ·२ घेनं।स्कंधांसीवकुलिशेनाविवृक्णा'हिःशयतेऽउपपृक्पृथिव्याः॥ ३६ ॥अयोद्धेवदुर्मदऽआ
२२ हिजुह्वे'महावीरंतुविबाधमृजीषं।नातारीदस्यसमृतिंवधानां'संरुजानाःपिपिषऽइंद्रशत्रुः॥अ
पादहस्तोऽअपृतन्यदिंद्र'मास्यवज्रमधिसानौजघान।वृष्णोवध्रिःप्रतिमानंबुभूष'न्पुरुत्रावृ
त्रोऽअशयद्व्यस्तः॥नदंनभिन्नममुयाशयानं'मनोरुहाणाऽअतियंत्यापः।याश्चिद्वृत्रोमहि
नापर्यतिष्ठ'त्तासामहिःपत्सुतःशीर्बभूव॥नीचावयाऽअभवद्वृत्रपुत्रे'द्रोऽअस्याऽअववधर्ज
भार।उत्तरासूरधरःपुत्रऽआसी'द्दानुःशयेसहवत्सानधेनुः॥अतिष्ठंतीनामनिवेशनानां'काष्ठा
नांमध्येनिहितंशरीरं।वृत्रस्यनिण्यंविचरंत्यापो'दीर्घंतमऽआशयदिंद्रशत्रुः॥ ३७ ॥दास
पत्नीरहिगोपाऽअतिष्ठन्निरुद्धाऽआपःपणिनेवगावः।अपांबिलमपिहितंयदासी'द्वृत्रंज २२
घन्वाँऽअपतद्ववार॥अश्व्योवारोऽअभवस्तदिंद्र'सृकेयत्वाप्रत्यहन्देवऽएकः।अजयोगाऽ

अजयः शूर सोममवासृजः सर्तवे सप्त सिंधून्॥ नास्मै विद्युन्न तन्यतुः सिषेध न यां मिहमकि
रद्ध्रादुनिं च। इंद्रश्च यद्युयुधाते अहिश्चोतापरीभ्यो मघवा विजिग्ये॥ अहेर्यातारं कमपश्य
इंद्र हृदि यत्ते जघ्नुषो भीरगच्छत्। नव च यन्नवतिं च स्रवंतीः श्येनो न भीतो अतरो रजांसि॥ इंद्रो
यातोवसितस्य राजा शमस्य च शृंगिणो वज्रबाहुः। सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि
ता बभूव॥ ३८ ॥ १५। २३। २८९ ॥ दासऽपत्नीः। अहिऽगोपाः। अतिष्ठन्। निऽरुद्धाः। आपः। प
णिनाऽइव। गावः। अपां। बिलं। अपिऽहितं। यत्। आसीत्। वृत्रं। जघन्वान्। अप। तत्। ववार। अ
श्व्यः। वारः। अभवः। तत्। इंद्र। सृके। यत्। त्वा। प्रतिऽअहन्। देवः। एकः। अजयः। गाः। अजयः।
शूर। सोमं। अव। असृजः। सर्तवे। सप्त। सिंधून्। न। अस्मै। विऽद्युत्। न। तन्युतुः। सिसेध। न। यां।
मिहं। अकिरत्। ह्रादुनिं। च। इंद्रः। च। यत्। युयुधाते इति। अहिः। च। उत। अपरीभ्यः। मघऽवा। वि।

सं॰प्र॰२ ज्ञिम्ये। अहेः। यातारं। कं। अपश्यः। इंद्र। हृदि। यत्। ते। जघ्नुषः। भीः। अगच्छत्। नव। च। यत्। नवतिं।
२३ च। स्रवंतीः। श्येनः। न। भीतः। अतरः। रजांसि। इंद्रः। यातः। अवऽसितस्य। राजा। शमस्य। च। शृंगि
णः। वज्रऽबाहुः। सः। इत्। ऊं इति। राजा। क्षयति। चर्षणीनां। अरान्। न। नेमिः। परि। ता। बभूव॥ ३१
इतिसंहिताप्रथमाष्टकेद्वितीयोध्यायः॥ ॥ ॐ ॥एतन्त्रिंश्चि हूदशाध्विनैनवम्यंत्येत्रिष्टुभौ
हृक्याम्येकादशास्ताविन्नैनवमीजगत्याद्याचसालिंगोक्तदेवतपादाप्रवोविंशतिःकण्वोघोरआग्ने
यंप्रागाथमूर्ध्वउपुयोद्यौश्रीवंपंचोनामारुतंहिगायत्रंतुकद्धमयहृदशाप्रागाथंत्वत्रिष्ठोष्टौब्रा
ह्मणस्पत्यैयंरक्षंतिनववरुणमित्रार्यम्णांमध्येतृचआदित्येभ्योगायत्रंहिसंपूषन्द्वैपोष्णंकद्रु श्री राम
द्रायनवरौद्रंतृतीयामैत्रावरुणीचांत्यस्तृचःसौम्योंत्यानुष्टुबग्नेषळूनांप्रस्कण्वःकाण्वआग्ने २३
यंतुप्रागाथमाद्योहृचोभ्युषसांत्वमग्नेदशानुष्टुभमर्धर्चौंत्योदैवेष्वोपंचोनाश्विनंतुगायत्रं॥२

॥ ॐ ॥ एतायामोपगव्यंतऽइंद्र'मस्माकंसुप्रमतिंवावृधाति। अनामृणःकुविदादस्यरायो'गवांके
तंपरमावर्जतेनः॥ उपेदहंधनदामप्रतीतं'जुष्टांनश्येनोवसतिंपतामि। इंद्रंनमस्यन्नुपमेभिरर्कैर्'यः
स्तोतृभ्योहव्योऽअस्तियामन्॥ निसर्वसेनऽइषुधीँरसक्त'समर्योगाऽअजतियस्यवष्टि। चोष्कूय
माणऽइंद्रभूरिवामं'मापणिर्भूरस्मदधिप्रवृद्ध॥ वधीर्हिदस्युंधनिनंघनेनँ'एकश्चरन्नुपशाकेभि
रिंद्र। धनोरधिविषुणक्तेव्यायन्नयज्वानःसनकाःप्रेतिमीयुः॥ पराचिच्छीर्षाववृजुस्तऽइंद्रायज्वा
नोयज्वभिःस्पर्द्धमानाः। प्रयद्दिवोहरिवःस्थातरुग्र'निरव्रताँऽअधमोरोदस्योः॥ १ ॥ अयुयुत्स
न्ननवद्यस्यसेनां'मयातयंतक्षितयोनवग्वाः। वृषायुधोनवध्रयोनिरष्टाः'प्रवद्भिरिंद्राच्चितयंतऽ
आयन्॥ त्वमेतान्रुदतोजक्षतश्चायोधयोरजसऽइंद्रपारे। अवादहोदिवऽआदस्युमुच्चाप्रसुन्व
तःस्तुवतःशंसमावः॥ चक्राणासःपरीणहंपृथिव्या'हिरण्येनमणिनाशुंभमानाः। नहिन्वाना

सं·प्र·३ सस्तितिरुस्तेऽइंद्रंपरिस्पशोऽअदधात्सूर्येण॥ परियदिंद्ररोदसीऽउभेऽअबुभोजीर्महिनाविश्वतः
२४ सीं। अमन्यमानाँऽअभिमन्यमानैर्निर्ब्रह्मभिरधमोदस्युमिंद्र॥ नयेदिवःपृथिव्याऽअंतमापुर्नमा
याभिर्धनदांपर्यभूवन्। युजंवज्रंवृषभश्चक्रऽइंद्रोनिर्ज्योतिषातमसोगाऽअदुक्षत्॥ २॥ अनु
स्वधामक्षरन्नापोऽअस्यावर्धतमध्यऽआनाव्यानां। सध्रीचीनेनमनसातमिंद्रऽओजिष्ठेनहन्मनाऽ
हन्नभिद्यून्॥ न्याविध्यदिलीबिशस्यदृह्ळाविशृंगिणमभिनच्छुष्णमिंद्रः। यावत्तरोमघवन्यावु
दोजोवज्रेणशत्रुमवधीःपृतन्युं॥ अभिसिध्मोऽअजिगादस्यशत्रून्वितिग्मेनवृषभेणापुरोभे
त्। संवज्रेणासृजद्वृत्रमिंद्रःप्रस्वांमतिमतिरच्छाशदानः॥ आवःकुत्समिंद्रयस्मिन्चाकन्प्रावो
युध्यंतंवृषभंदशद्युं। शफच्युतोरेणुर्नक्षतद्यामुच्छ्वैत्रेयोनृषाह्यायतस्थौ॥ आवःशमंवृषभं २५
तुग्र्यासुक्षेत्रजेषेमघवञ्छ्वित्र्यंगां। ज्योक्चिदत्रतस्थिवांसोऽअक्रञ्छत्रूयतामधरावेदनाकः

॥ ३ ॥ १५ त्रिश्चिन्नो ऽअद्या भवतं नवेदसा विभुर्वां याम ऽउत रातिरश्विना । युवोर्हि यंत्रं हिम्येव
वाससो ऽभ्यायंसेन्या भवतं मनीषिभिः ॥ त्रयः पवयो मधुवाहने रथे सोमस्य वेनामनु विश्व ऽ
इद्विदुः । त्रयः स्कंभासः स्कभितास ऽआरभे त्रिर्नक्तं याथस्त्रिर्वश्विना दिवा ॥ समाने ऽअहन्त्रिर
वद्यगोहना त्रिरद्य यज्ञं मधुना मिमिक्षतं । त्रिर्वाजवतीरिषो ऽअश्विना युवं दोषा ऽअस्मभ्यमुषस
श्च पिन्वतं ॥ त्रिर्वर्तिर्यातं त्रिरनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतं । त्रिर्नान्द्यं वहतमश्विना युवं त्रिः
पृक्षो ऽअस्मे ऽअक्षरेव पिन्वतं ॥ त्रिर्नो रयिं वहतमश्विना युवं त्रिर्देवताता त्रिरुतावतं धियः । त्रिः सौ
भगत्वं त्रिरुत श्रवांसि नस्त्रिष्ठं वां सूरे दुहिता रुहद्रथं ॥ त्रिर्नो ऽअश्विना दिव्यानि भेषजा त्रिः पा
र्थिवानि त्रिरु दत्तमद्भ्यः । ओमानं शंयोर्ममकाय सूनवे त्रिधातु शर्म वहतं शुभस्पती ॥ ४ ॥ त्रि
र्नो ऽअश्विना यजता दिवेदिवे परि त्रिधातु पृथिवीमशायतं । तिस्रो नासत्या रथ्या परावत ऽआ

सं·अ·३ त्येववातःस्वसराणिगच्छतं॥त्रिरश्विनासिंधुभिःसप्तमातृभिस्त्रयऽआहावास्त्रेधाहविष्कृतं।ति
२५ स्रःपृथिवीरुपरिप्रवादिवो'नाकंरक्षेथेद्युभिरक्तुभिर्हितं॥क्व१त्रीचक्रात्रिवृतोरथस्य'क्व१त्रयोवं
धुरोयेसनीळाः।कदायोगोवाजिनोरासभस्य'येनयज्ञंनासत्योपयाथः॥आनासत्यागच्छतंहू
यतेहविर्मध्वःपिबतंमधुपेभिरासभिः।युवोर्हिपूर्वंसवितोषसोरथ'मृतायचित्रंघृतवंतमिष्य
ति॥आनासत्यात्रिभिरेकादशैरिह'देवेभिर्यातंमधुपेयमश्विना।प्रायुस्तारिष्टंनीरपांसिमृक्ष
तंसेधतंद्वेषोभवतंसचाभुवा॥आनोऽअश्विनात्रिवृतारथेना'र्वांचंरयिंवहतंसुवीरं।शृण्वंता
वामवसेजोहवीमि'वृधेचनोभवतंवाजसातौ॥ ५ ॥१२ ह्वयाम्यग्निंप्रथमंस्वस्तये'ह्वया
मिमित्रावरुणाविहावसे।ह्वयामिरात्रींजगतोनिवेशनीं'ह्वयामिदेवंसवितारमूतये॥आकृष्णे २५
नरजसावर्तमानो'निवेशयन्नमृतंमर्त्यंच।हिरण्ययेनसवितारथे'नादेवोयातिभुवनानिप

55

श्यन्॥याति देवः प्रवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्यां।आ देवो याति सविता परावतो
ऽप विश्वा दुरिता बाधमानः॥अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहंतं।आस्थाद्रथं
सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः॥वि जनाञ्छ्यावाः शितिपादोऽअख्यन्रथं हिर
ण्यप्रऽउगं वहंतः।शश्वद्विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः॥तिस्रो द्यावः सवितुर्द्वाऽ
उपस्थाँऽएका यमस्य भुवने विराषाट्।आणिं न रथ्यममृताधि तस्थुरिह ब्रवीतु यऽउ तच्चिकेत
तत्॥ ६ ॥वि सुपर्णोऽअंतरिक्षाण्यख्यद्गभीरवेपाऽअसुरः सुनीथः।क्वेदानीं सूर्यः कश्चिकेत क
तमां द्यां रश्मिरस्या ततान॥अष्टौ व्यख्यत्ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिंधून्।हिरण्याक्षः
सविता देवऽआगाद्दधद्रत्ना दाशुषे वार्याणि॥हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवीऽ
अंतरीयते।अपामीवां बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति॥हिरण्यहस्तोऽअसुरः सु

सं·प्र·३ नीथः'सुमृळीकः स्ववाँ यात्वर्वाङ्।अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः॥येते पं
२६ थाः सवितः पूर्व्यासो'रेणवः सुकृता ऽअंतरिक्षे।तेभिर्नोऽअद्य पथिभिः सुगेभी'रक्षा च नोऽअधि च
ब्रूहि देव॥ ७ ॥ ११ अनुवाकः॥ ७ प्रवोयह्वं पुरूणां'विशां देवयतीनां॥अग्निं सूक्तेभिर्वचोभि
रीमहे'यंसीमिदन्यऽईळते॥ऊर्नासोऽअग्निं दधिरे सहोवृधं'हविष्मंतो विधेमते।सत्वंनोऽअद्य
सुमनाऽइहाविता'भवा वाजेषु संत्य॥प्रत्वा दूतं वृणीमहे'होतारं विश्ववेदसं।महस्ते सतो विच
रंत्यर्चयो'दिविस्पृशंति भानवः॥देवासस्त्वा वरुणो मित्रोऽअर्यमा'संदूतं प्रत्नमिंधते।विश्वं
सोऽअग्ने जयति त्वया धनं'यस्ते ददाश मर्त्यः॥मंद्रो होता गृहपति'रग्ने दूतो विशामसि।त्वे वि राम
श्वा संगतानि व्रता'ध्रुवा यानि देवाऽअकृण्वत॥ ८ ॥त्वेऽइदग्ने सुभगे यविष्ठ्य'विश्वमाहूयते २६
हविः।सत्वंनोऽअद्य सुमनाऽउतापरं'यक्षि देवान्त्सुवीर्या॥तं घेमित्था नमस्विनऽ'उपस्वराज

मासते।होत्राभिरग्निंमनुषःसमिंधते'तितिर्वांसोऽअतिस्रिधः॥घ्नंतोवृत्रमतरन्रोदसीऽअपऽउरु
क्षयायचक्रिरे।भुवत्कण्वेवृषाद्युम्न्याहुतः'क्रंददश्वोगविष्टिषु॥संसीदस्वमहाँऽअसि'शोचस्वदे
ववीतमः।विधूममग्नेऽअरुषंमियेध्य'सृजप्रशस्तदर्शतं॥यंत्वादेवासोमनवेदधुरिह'यजिष्ठं
हव्यवाहन।यंकण्वोमेध्यातिथिर्धनस्पृतं'यंवृषायमुपस्तुतः॥ ॥यमग्निंमेध्यातिथिः'कण्व
ऽईधऽऋतादधि।तस्यप्रेषोदीदियुस्तमिमाऽऋचस्तमग्निंवर्धयामसि॥रायस्पूर्धिस्वधावो
ऽस्तिहितेऽग्नेदेवेष्वाप्यं।त्वंवाजस्यश्रुत्यस्यराजसि'सनोमृळमहाँऽअसि॥ऊर्ध्वऽऊषुणऽऊतये'
तिष्ठादेवोनसविता।ऊर्ध्वोवाजस्यसनितायदंजिभिर्वाघद्भिर्विह्वयामहे॥ऊर्ध्वोनःपाह्यंहसो
निकेतुना'विश्वंसमत्रिणंदह।कृधीनऽऊर्ध्वांचरथायजीवसे'विदादेवेषुनोदुवः॥पाहिनोऽअग्ने
रक्षसः'पाहिधूर्तेरराव्णः।पाहिरीषतऽउतवाजिघांसतो'बृहद्भानोयविष्ठ्य॥ १० ॥घनेवविष्व

सं·प्र·३ ग्विज्जहाराव्या'स्तपुर्जंभयो ऽ अस्मध्रुक्‌। योमर्त्यःशिशीते ऽ अत्यक्तुभि'र्मानःसरिपुरीशात॥ अग्नि
२७ र्वैंद्रेसुवीर्यं'मग्निःकण्वायसोभगं। अग्निःप्रावन्मित्रोतमेध्यातिथि'मग्निःसाता ऽ उपस्तुतं॥ अ
ग्निनातुर्वशंयदुंपरावतः ऽ उग्रादेवंहवामहे। अग्निर्नयन्नववास्त्वंबृहद्रथं'तुर्वीतिंदस्यवेसहः
॥ नित्वामग्नेमनुर्दधे'ज्योतिर्जनायशश्वते। दीदेथकण्व ऽ ऋतजात ऽ उक्षितो'यंनमस्यंतिकृ
ष्टयः॥ त्वेषासो ऽ अग्नेरमवंतो ऽ अर्चयो'भीमासोनप्रतीतये। रक्षस्विनःसदमिद्यातुमावतो
१०। विश्वंसमत्रिणंदह॥ ११ ॥ २० क्रीळंवःशर्धोमारुतं'मनर्वाणंरथेशुभं। कण्वा ऽ अभिप्रगाय
त॥ येपृषतीभिर्ऋष्टिभिः साकंवाशीभिरंजिभिः। अजायंतस्वभानवः॥ इहेवशृण्व ऽ एषां'क शिव
शाहस्तेषुयद्वदान्। नियामेंचित्रमृंजते॥ प्रवःशर्धायघृष्वये'त्वेषद्युम्नायशुष्मिणे। देवत्तं २७
ब्रह्मगायत॥ प्रशंसागोष्वघ्न्यं'क्रीळंयच्छर्धोमारुतं। जंभेरसस्यवावृधे॥ १२ ॥ कोवोवर्षिष्ठ ऽ

आ नरो' दिव श्च ग्मश्च धूतयः। यत्सीमंतंन धूनुथ॥ निवो यामाय मानुषो' दध्र ऽउग्राय मन्यवे। जि
हीत पर्वतो गिरिः॥ येषामज्मेषु पृथिवी' जुजुर्वां ऽइव विश्पतिः। भिया यामेषु रेजते॥ स्थिरं हि जा
नमेषां' वयो मातुर्निरेतवे। यत्सीमनु द्विता शवः॥ उदु त्ये सूनवो गिरः' काष्ठा ऽअज्मेष्वत्नत। वाश्रा ऽ
अभिज्ञु यातवे॥ २३ ॥ त्यं चिद्घा दीर्घं पृथुं' मिहो नपातममृध्रं। प्र च्यावयंति यामभिः॥ मरुतो यद्ध
वो बलं' जनाँ ऽअचुच्यवीतन। गिरीँ रचुच्यवीतन॥ यद्ध यांति मरुतः' सं ह ब्रुवते ध्वन्ना। शृणो
ति कश्चिदेषां॥ प्र यात शीभमाशुभिः' संति कण्वेषु वो दुवः। तत्रो षु मादयाध्वै॥ अस्ति हि ष्मा मदाय
वः' स्मसि ष्मा वयमेषां। विश्वं चिदायुर्जीवसे॥ २४ ॥ कद्ध नूनं कधप्रियः' पिता पुत्रं न हस्तयोः।
दधिध्वे वृक्तबर्हिषः॥ क्व नूनं कद्वो ऽअर्थं' गंता दिवो न पृथिव्याः। क्व वो गावो न रण्यंति॥ क्व वः सु
म्ना नव्यांसि' मरुतः क्व सुविता। को ३ विश्वानि सौभगा॥ यद्यूयं पृश्निमातरो' मर्तासः स्यातन। स्तो

सं·अ·२ तावो ऽअमृतः स्यात॥ मावोमृगो नयवसे जरिता भूदजोष्यः। पथायमस्य गादुप॥ १५ ॥ मोषुणः प
२८ रापरा निर्ऋतिर्दुर्हणा वधीत्। पदीष्टतृष्णया सह॥ सत्यंत्वेषा ऽअमवंतो धन्वंच्चिदारुद्रियासः। मि
हंकृण्वंत्यवाता॥ वाश्रेवविद्युन्मिमाति वत्संनमाता सिषक्ति। यदेषांवृष्टिरसर्जि॥ दिवाचित्तमः कृ
ण्वंति पर्जन्येनोदवाहेन। यत्पृथिवींव्युंदंति॥ अधस्वनान्मरुतां विश्वमासद्मपार्थिवं। अरेजंत
प्रमानुषाः॥ १६ ॥ मरुतोवीळुपाणिभिश्चित्रारोधस्वतीरनु। यातेमखिद्रयामभिः॥ स्थिरावः
संतुनेमयो रथा ऽअश्वास ऽएषां। सुसंस्कृता ऽअभीशवः॥ अच्छावदातनागिरा जरायैब्रह्म
णस्पतिं। अग्निंमित्रंनदर्शतं॥ मिमीहिश्लोकमास्ये पर्जन्य ऽइवततनः। गायगायत्रमुक्थ्यं॥ राम
वंदस्वमारुतंगणं त्वेषंपनस्युमर्किणं। अस्मेवृद्धा ऽअसन्निह॥ १७ ॥१५ प्रयदित्थापरा २९
वतः शोचिर्नमानमस्यथ। कस्यक्रत्वामरुतः कस्यवर्पसा कंयाथकंहधूतयः॥ स्थिरावः सं

त्वायुधा पराणुदे वीळू ऽ उत प्रतिष्कभे। युष्माकमस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः॥ परा
ह यत्स्थिरं हथ नरो वर्तयथा गुरु। वि याथन वनिनः पृथिव्या व्याशाः पर्वतानां॥ नहि वः श
त्रुर्विविदे ऽ अधि द्यवि न भूम्यां रिशादसः। युष्माकमस्तु तविषी तना युजा रुद्रासो नू चिदाधृ
षे॥ प्र वेपयंति पर्वतान्वि विंचंति वनस्पतीन्। प्रो ऽ आरत मरुतो दुर्मदा ऽ इव देवासः सर्वया विशा
॥ १८ ॥ उपो रथेषु पृषतीरयुग्ध्वं प्रष्टिर्वहति रोहितः। आ वो यामाय पृथिवी चिदश्रोदबीभयंत मा
नुषाः॥ आ वो मक्षू तनाय कं रुद्रा ऽ अवो वृणीमहे। गंता नूनं नोवसा यथा पुरेत्था कण्वाय बिभ्युषे
॥ युष्मेषितो मरुतो मर्त्येषित ऽ आ यो नो ऽ अभ्व ऽ ईषते। वि तं युयोत शवसा व्योजसा वि युष्माका
भिरूतिभिः॥ असामि हि प्रयज्यवः कण्वं दद प्रचेतसः। असामिभिर्मरुत ऽ आ न ऽ ऊतिभिर्गंता
वृष्टिं न विद्युतः॥ असाम्योजो बिभृथा सुदानवोसामि धूतयः शवः। ऋषिद्विषे मरुतः परिमन्य

सं·अ·३ वेऽइषुं न सृजत द्विषं॥ १९ ॥ १० उत्तिष्ठ ब्रह्मणस्पते देवयंतस्त्वेमहे। उप प्र यंतु मरुतः सुदान
२९ वेऽइंद्र प्राशूर्भवा सचा॥ त्वामिद्धि सहसस्पुत्र मर्त्यऽउपब्रूते धने हिते। सुवीर्यं मरुतऽआ स्वश्व्यं द
धीत यो वऽआचके॥ प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता। अच्छा वीरं नर्यं पंक्तिराधसं देवा यज्ञं ने
यंतु नः॥ यो वाघते ददाति सूनरं वसु स धत्तेऽअक्षिति श्रवः। तस्माऽइळां सुवीरामा यजामहे सु
प्रतूर्तिमनेहसं॥ प्र नूनं ब्रह्मणस्पतिर्मंत्रं वदत्युक्थ्यं। यस्मिन्निंद्रो वरुणो मित्रोऽअर्यमा देवाऽ
ओकांसि चक्रिरे॥ २० ॥ तमिद्वोचेमा विदथेषु शंभुवं मंत्रं देवाऽअनेहसं। इमां च वाचं प्रतिह
र्यथा नरो विश्वेद्वामा वोऽअश्नवत्॥ को देवयंतमश्नवज्जनं को वृक्तबर्हिषं। प्रप्र दाश्वान्पस्त्या राम
भिरस्थितांतर्वावत्क्षयं दधे॥ उप क्षत्रं पृंचीत हंति राजभिर्भये चित्सुक्षितिं दधे। नास्य वर्ता न २९
तरुता महाधने नार्भेऽअस्ति वज्रिणः॥ २१ ॥ ८ यं रक्षंति प्रचेतसो वरुणो मित्रोऽअ ३१२

येमा।नूचित्सदभ्यतेजनः॥यंबाहुतेवपिप्रतिपांतिमर्त्यंरिषः।अरिष्टःसर्वऽएधते॥विदुर्गा
विद्विषःपुरोघ्नंतिराजानऽएषां।नयंतिदुरितातिरः॥सुगःपंथाऽअनृक्षरऽआदित्यासऽऋ
तंयते।नात्रावखादोऽअस्तिवः॥यंयज्ञंनयथानरऽआदित्याऽऋजुनापथा।प्रवःसधीतये
नशत्॥ २२ ॥सरत्नंमर्त्योवसुविश्वंतोकमुतत्मना।अच्छागच्छत्यस्तृतः॥कथाराधामसखा
यःस्तोमंमित्रस्यार्यम्णः।महिप्सरोवरुणस्य॥मावोघ्नंतंमाशपंतंप्रतिवोचेदेवयंतं।सुम्नैरि
द्वऽआविवासे॥चतुरश्चिद्ददमानाद्बिभीयादानिधातोः।नदुरुक्तायस्पृहयेत्॥ २३ ॥
संपूषन्नध्वनस्तिरव्यंहोविमुचोनपात्।सक्ष्वादेवप्रणस्पुरः॥योनःपूषन्नघोवृकोदुःशेवऽ
आदिदेशति।अपस्मतंपथोजहि॥अपत्यंपरिपंथिनंमुषीवाणंहुरश्चितं।दूरमधिस्रुते
रज॥त्वंतस्यद्वयाविनोघशंसस्यकस्यचित्।पदाभितिष्ठतपुषिं॥आतत्तेदस्रमंतुमःपूषन्नवो

सं॰प्र॰३ वृणीमहे। येनेपितॄनचोदयः॥ २४ ॥अधानोविश्वसौभग'हिरण्यवाशीमत्तम। धनानिसुषणा
३० कृधि॥अतिनःसश्चतोनयंसुगानःसुपथाकृणु। पूषन्निहक्रतुंविदः॥अभिसूयवसंनय'नन
वज्वारोऽअध्वने। पूषन्निह०॥शग्धिपूर्धिप्रयंसिचंशिशीहिप्रास्युदरं'पूषन्निह०॥नपूषणंमे
थामसि'सूक्तैरभिगृणीमसि। वसूनिदस्ममीमहे॥ २५ ॥१० कद्रुद्रायप्रचेतसे'मीढुष्टमा
यतव्यसे। वोचेमशंतमंहृदे॥यथानोऽअदितिःकरत्पश्वेनृभ्योयथागवे। यथातोकायरुद्रियं॥
यथानोमित्रोवरुणो'यथारुद्रश्चिकेतति। यथाविश्वेसजोषसः॥गाथपतिंमेधपतिं'रुद्रंजला
षभेषजं। तच्छंयोःसुम्नमीमहे॥यःशुक्रऽइवसूर्यो'हिरण्यमिवरोचते। श्रेष्ठोदेवानांवसुः॥
॥ २६ ॥शंनःकरत्यर्वते'सुगंमेषायमेष्ये। नृभ्योनारिभ्योगवे॥अस्मेसोमश्रियमधि'निधेहि ३०
शतस्यनृणां। महिश्रवस्तुविनृम्णं॥मानःसोमपरिबाधो'मारातयोजुहुरंत। आनऽइंदोवाजे

भज॥यास्तेप्रजाऽअमृतस्य'परस्मिन्धामन्नृतस्य।मूर्धानाभासोमवेनऽ'आभूषंतीःसोमवेदः॥
॥ २७ ॥ ७ अनुवाकः॥ ८ अग्नेविवस्वदुषस'श्चित्रंराधोऽअमर्त्य।आदाशुषेजातवेदोव
हात्वमद्यादेवाँउषर्बुधः॥जुष्टोहिदूतोऽअसिहव्यवाहनो'ग्नेरथीरध्वराणां।सजूरश्विभ्या
मुषसासुवीर्य'मस्मेधेहिश्रवोबृहत्॥अद्यादूतंवृणीमहे'वसुमग्निंपुरुप्रियं।धूमकेतुंभाऽ
ऋजीकंव्युष्टिषु'यज्ञानामध्वरश्रियं॥श्रेष्ठंयविष्ठमतिथिंस्वाहुतं'जुष्टंजनायदाशुषे।देवाँ
अच्छायातवेजातवेदस'मग्निमीळेव्युष्टिषु॥स्तविष्यामित्वामहं'विश्वस्यामृतभोजन।अग्ने
त्रातारममृतंमियेध्य'यजिष्ठंहव्यवाहन॥ २८ ॥सुशंसोबोधिगृणतेयविष्ठ्य'मधुजिह्वःस्वा
हुतः।प्रस्कण्वस्यप्रतिरन्नायुर्जीवसे'नमस्यादैव्यंजनं॥होतारंविश्ववेदसं'संहित्वाविशऽइंध
ते।सऽआवहपुरुहूतप्रचेतसो'ग्नेदेवाँइहद्रवत्॥सवितारमुषसमश्विनाभगं'मग्निंव्युष्टि

सं·प्र·३ सुक्षपः। कण्वासस्त्वा सुतसोमास ऽ इंधते हव्यवाहं स्वध्वर॥ पतिं ह्यध्वराणामग्ने दूतो विशाम
३१ सि। उषर्बुध ऽ आवह सोमपीतये देवाँ ऽ अद्य स्वर्दृशः॥ अग्ने पूर्वा ऽ अनूषसो विभावसो दीदे
थ विश्वदर्शतः। असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः॥ २९ ॥ नित्वा यज्ञस्य साधन
मग्ने होतारमृत्विजं। मनुष्वद्देव धीमहि प्रचेतसं जीरं दूतममर्त्यं॥ यद्देवानां मित्रमहः पुरोहितो
ऽन्तरो यासि दूत्यं। सिंधोरिव प्रस्वनितास ऽ ऊर्मयोऽग्नेर्भ्राजंते ऽ अर्चयः॥ श्रुधि श्रुत्कर्ण वह्निभि
र्देवैरग्ने सयावभिः। आसीदंतु बर्हिषि मित्रो ऽ अर्यमा प्रातर्यावाणो ऽ अध्वरं॥ शृण्वंतु स्तोमं
मरुतः सुदानवोऽग्निजिह्वा ऽ ऋतावृधः। पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः
॥ ३० ॥ १४ त्वमग्ने वसूँरिह रुद्राँ आदित्याँ उत। यजा स्वध्वरं जनं मनुजातं घृतप्रुषं॥ ३१
श्रुष्टीवानो हि दाशुषे देवा ऽ अग्ने विचेतसः। तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमावह॥ प्रियमे

धवदत्रिवज्जातवेदो विरूपवत्। अंगिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवं॥ महिकेरवऽऊतये प्रि
यमेधाऽअहूषत। राजंतमध्वराणामग्निं शुक्रेण शोचिषा॥ घृताहवनसंत्येमाऽउषुश्रुधी गिरः।
याभिः कण्वस्य सूनवो हवंतेवसे त्वा॥ ३१ ॥ त्वां चित्रश्रवस्तम हवंते विक्षु जंतवः। शोचिष्केशं पु
रुप्रियाग्ने हव्याय वोळ्हवे॥ नित्वा होतारमृत्विजं दधिरे वसुवित्तमं। श्रुत्कर्णं सप्रथस्तमं विप्राऽ
अग्ने दिविष्टिषु॥ आत्वा विप्राऽअचुच्यवुः सुतसोमाऽअभिप्रयः। बृहद्भा बिभ्रतो हविरग्ने मर्त्ता
य दाशुषे॥ प्रातर्याव्णः सहस्कृत सोमपेयाय संत्य। इहाद्य दैव्यं जनं बर्हिरासादया वसो॥ अर्वांचं दै
व्यं जनमग्ने यक्ष्व सहूतिभिः। अयं सोमः सुदानवस्तं पात तिरोऽअह्न्यं॥ ३२ ॥ १ एषोऽउषा
ऽअपूर्व्या व्युच्छति प्रिया दिवः। स्तुषे वामश्विना बृहत्॥ या दस्रा सिंधुमातरा मनोतरा रयीणां।
धिया देवा वसुविदा॥ वच्यंते वां ककुहासो जूर्णायामधि विष्टपि। यद्वां रथो विभिष्पतात्॥ हवि

सं·अ·३ षो जारोऽअपां'पिपर्ति पपुरिर्नरा।पिता कुटस्य चर्षणिः॥आदारो वांमतीनां'नासत्या मतवचसा।
३२ पातं सोमस्य धृष्णुया॥ ३३ ॥या नः पीपरदश्विनाऽज्योतिष्मती तमस्तिरः।तामस्मे रासाथामिषं॥
आ नो नावा मतीनां'यातं पाराय गंतवे।युंजाथामश्विना रथं॥अरित्रं वां दिवस्पृथु'तीर्थे सिंधूनां र
थः।धिया युयुज्रऽइंदवः॥दिवस्कण्वासऽइंदवो'वसु सिंधूनां पदे।स्वं वव्रिं कुह धित्सथः॥अभू
दु भाऽउऽअंशवे हिरण्यं प्रति सूर्यः।व्यख्यज्जिह्वयासितः॥ ३४ ॥अभूदु पारमेतवे'पंथाऽ
ऋतस्य साधुया।अदर्शि विस्रुतिर्दिवः॥तत्तदिदश्विनोरवो'जरिता प्रति भूषति।मदे सोमस्य
पिप्रतोः॥वावसाना विवस्वति'सोमस्य पीत्या गिरा।मनुष्वच्छंभूऽआगतं॥युवोरुषाऽअनु श्रि
यं'परिज्मनोरुपाचरत्।ऋता वनथोऽअक्तुभिः॥उभा पिबतमश्विनो'भा नः शर्म यच्छतं। ३२
अविद्रियाभिरूतिभिः॥ ३५ ॥ १५ ॥ १४ ॥ १७३ ॥अभूत्।ऊं इति।पारं।एतवे।पंथाः।ऋतस्य।

साधुऽया। अदर्शि। वि। स्तुतिः। दिवः। ततऽतेत्। इत्। अश्विनोः। अवः। जरिता। प्रति। भूषति। म
दे। सोमस्य। पिप्रतोः। ववसाना। विवस्वति। सोमस्य। पीत्या। गिरा। मनुष्वत्। शंभू इति शंऽभू। आ।
गतं। युवोः। उषाः। अनु। श्रियं। परिऽज्मनोः। उपऽआ। चरत्। ऋता। वनथः। अक्तुऽभिः। उभा। पि
बतं। अश्विना। उभा। नः। शर्म। यच्छतं। अविद्रियाभिः। ऊतिऽभिः॥ ३५ ॥ इति संहिता प्रथ
माष्टके तृतीयोध्यायः॥ ॥ ॐ ॥ अयंदशप्रागाथंतुसहषोळशोषस्यंत्वेषश्चतुष्कमानु
ष्टुभंतूदुत्यंसप्तोनासोयैंनवाद्यागायत्र्योंत्यस्तृचोरोगघ्नउपनिषदंत्योर्द्धचौद्विषघ्नोभित्यं
पंचोनासव्योहित्रिष्टुबंतमंगिराऽइंद्रतुल्यंपुत्रमिच्छन्नभ्यध्यायत्सस्वयइंतीद्रएवास्यपुत्रो
जायततंत्यंसुत्रयोदश्यंत्येत्रिष्टुभौन्यूषेकादशांत्येत्रिष्टुभौमानोंत्यात्रिष्टुप्पूर्षष्यष्टमीनवमी
चद्विवश्विदष्टौजागतंह्येषप्रषट्प्रमेहिष्टायंनूचित्त्रवनोधागोतमऽआग्नेयंहिचतुस्त्रिष्टु

सं·ग्र·४ बंतंवयाइत्सप्तवैश्वानरीयंवह्निंपंचास्माद्दुषोळ्शा॥ ४ ॥ ॐ ॥अयंवांमधुमत्तमः'सुतः
३२ सोमऽऋतावृधा।तमश्विनापिबतंतिरोऽअह्न्यं'धत्तंरत्नानिदाशुषे॥त्रिवंधुरेणत्रिवृतासुपे
शसा'रथेनायातमश्विना।कण्वासोवांब्रह्मकृण्वंत्यध्वरे'तेषांसुशृणुतंहवं॥अश्विनामधु
मत्तमं'पातंसोममृतावृधा।अथाद्यदस्रावसुबिभ्रतारथे'दाश्वांसमुपगच्छतं॥त्रिषधू
स्थेबर्हिषिविश्ववेदसा'मध्वायज्ञंमिमिक्षतं।कण्वासोवांसुतसोमाऽअभिद्यवो'युवांहवंतेऽ
अश्विना॥याभिःकण्वमभिष्टिभिः'प्रावतंयुवमश्विना।ताभिःषू१स्माँअवतंशुभस्पती'पा
तंसोममृतावृधा॥ १ ॥सुदासेदस्रावसुबिभ्रतारथे'पृक्षोवहतमश्विना।रयिंसमुद्रादुतवा
दिवस्पर्यस्मेधत्तंपुरुस्पृहं।यन्नासत्यापरावति'यद्वास्थोऽअधितुर्वशे।अतोरथेनसुवृता ३२
नऽआगतं'साकंसूर्यस्यरश्मिभिः॥अर्वांचावांसप्तयोध्वरश्रियो'वहंतुसवनेदुप।इषंपृंचंता

सुहूते सुदानव ऽआ बर्हिः सीदतं नरा ॥ तेन नासत्यागतं रथेन सूर्यत्वचा । येन शश्वदूहथुर्दा
शुषे वसु मध्वः सोमस्य पीतये ॥ उक्थेभिरर्वागवसे पुरूवसू ऽअर्कैश्च नि ह्वयामहे । शश्वत्क
ण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना ॥ २ ॥ १० सह वामेन न ऽउषो व्युच्छा दुहितर्दि
वः । सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥ अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवं
त वस्तवे । उदीरय प्रति मा सूनृता ऽउषश्चोद राधो मघोनां ॥ उवासोषा ऽउच्छाच्च नु देवी जीरा
रथानां । ये ऽअस्या ऽआचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥ उषो ये ते प्र यामेषु युंजते मनो
दानाय सूरयः । अत्राह तत्कण्व ऽएषां कण्वतमो नाम गृणाति नृणां ॥ आ घा योषेव सूनर्युषा
याति प्रभुंजती । जरयंती वृजनं पद्वदीयत ऽउत्पातयति पक्षिणः ॥ ३ ॥ वि या सृजति समनं व्य
र्थिनः पदं न वेत्योदती । वयो नकिष्टे पप्तिवांस ऽआसते व्युष्टौ वाजिनीवति ॥ एषायुक्त परावतः स

सं॰प्र॰४ र्यस्योदयनादधि। शतं रथेभिः सुभगोषाऽइयं वि यात्यभि मानुषान्॥ विश्वमस्या नानाम चक्ष
३५ से जगज्ज्योतिष्कृणोति सूनरी। अप द्वेषो मघोनी दुहिता दिवऽउषाऽउच्छदप स्रिधः॥ उषऽ
आ भाहि भानुना चन्द्रेण दुहितर्दिवः। आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु॥ विश्व
स्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि। सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे ह
वं॥ ४ ॥ उषो वाजं हि वंस्व यश्चित्रो मानुषे जने। तेना वह सुकृतोऽअध्वराँऽउप ये त्वा गृणन्ति
वह्नयः॥ विश्वान्देवाँऽआवह सोमपीतयेऽन्तरिक्षादुषस्त्वं। सास्मासु धा गोमदश्वावदुक्थ्यमु
षो वाजं सुवीर्यं॥ यस्या रुशन्तोऽअर्चयः प्रति भद्राऽअदृक्षत। सा नो रयिं विश्ववारं सुपेश
समुषा ददातु सुग्म्यं॥ ये चिद्धि त्वामृषयः पूर्वऽऊतये जुहूरेऽवसे महि। सा नः स्तोमाँऽअभि ३५
गृणीहि राधसोषः शुक्रेण शोचिषा॥ उषो यदद्य भानुना वि द्वारावृणवो दिवः। प्र नो यच्छ

तादवृकंपृथुच्छर्दिः'प्रदेविगोमतीरिषः॥संनोराया बृहताविश्वपेशसा'मिमिक्ष्वासमिळाभि
रा॥संद्युम्नेनविश्वतुरोषोमहि'संवाजैर्वाजिनीवति॥ ५ ॥१६ उषोभद्रेभिरागहि'दिवश्चिद्रो
चनादधि॥वहंत्वरुणप्सव'उपत्वासोमिनोगृहं॥सुपेशसंसुखंरथं'यमध्यस्थाऽउषस्त्वं॥ते
नासुश्रवसंजनं'प्रावाद्यदुहितर्दिवः॥वयश्चित्तेपतत्रिणो'द्विपच्चतुष्पदर्जुनि॥उषःप्रारन्नृ
तूँरनु'दिवोऽअंतेभ्यस्परि॥व्युच्छंतीहिरश्मिभि'र्विश्वमाभासिरोचनं॥तांत्वामुषर्वसूयवो'गी
र्भिःकण्वाऽअहूषत॥ ६ ॥ ४ उदुत्यंजातवेदसं'देवंवहंतिकेतवः॥दृशेविश्वायसूर्यं॥अ
पत्येतायवोयथा'नक्षत्रायंत्यक्तुभिः॥सूरायविश्वचक्षसे॥अदृश्रमस्यकेतवो'विरश्मयोज
नाँ॥अनु॥भ्राजंतोऽअग्नयोयथा॥तरणिर्विश्वदर्शतो'ज्योतिष्कृदसिसूर्य॥विश्वमाभासिरोच
नं॥प्रत्यङ्देवानांविशः'प्रत्यङ्ङुदेषिमानुषान्॥प्रत्यङ्विश्वंस्वर्दृशे॥ ७ ॥येनापावकचक्षसा'

सं॰प्र॰४ भुरण्यंतंजनाँ॥ अनु। त्वंवरुणपश्यसि॥ विद्यामेषिरजस्पृथ्वहामिमानोऽअक्तुभिः। पश्यञ्जन्मा
३५ निसूर्य॥ सप्तत्वाहरितोरथेवहंतिदेवसूर्य। शोचिष्केशंविचक्षण॥ अयुक्तसप्तशुंध्युवःसूरोर
थस्यनप्त्यः। ताभिर्यातिस्वयुक्तिभिः॥ उद्वयंतमसस्परिज्योतिष्पश्यंतऽउत्तरं। देवंदेवत्रासूर्य
मगन्मज्योतिरुत्तमं॥ उद्यन्नद्यमित्रमहऽआरोहन्नुत्तरांदिवं। हृद्रोगंममसूर्यहरिमाणंचना
शय॥ शुकेषुमेहरिमाणंरोपणाकासुदध्मसि। अथोहारिद्रवेषुमेहरिमाणंनिदध्मसि॥ उद
गादयमादित्योविश्वेनसहसासह। द्विषंतंमह्यंरंधयन्मोऽअहंद्विषतेरधं॥ ८ ॥ १३ अ
नुवाकः॥ ९ अभित्यंमेषंपुरुहूतमृग्मियमिंद्रंगीर्भिर्मदतावस्वोऽअर्णवं। यस्यद्यावोन
विचरंतिमानुषाभुजेमंहिष्ठमभिविप्रमर्चत॥ अभीमवन्वन्त्स्वभिष्टिमूतयोंतरिक्षप्रांतवि ३५
षीभिरावृतं। इंद्रंदक्षासऽऋभवोमदच्युतंशतक्रतुंजवनीसूनृतारुहत्॥ त्वंगोत्रमंगिरोभ्यो

वृणोरपोतात्रयेशतदुरेषुगातुवित्।ससेनचिद्विमदायावहोवस्वाजावद्रिंवावसानस्यनर्तयन्॥
त्वमपामपिधानावृणोरपाधारयःपर्वतेदानुमद्वसु।वृत्रंयदिंद्रशवसावधीरहिमादित्सूर्यंदिव्या
रोहयोदृशे॥त्वंमायाभिरपमायिनोऽधमःस्वधाभिर्येऽअधिशुप्तावजुह्वत।त्वंपिप्रोर्नृमणःप्रारु
जःपुरःप्रऽऋजिश्वानंदस्युहत्येष्वाविथ॥ १ ॥त्वंकुत्संशुष्णहत्येष्वाविथारंधयोतिथिग्वाय
शंबरं।महांतंचिदर्बुदंनिक्रमीःपदा।सनादेवदस्युहत्यायजज्ञिषे॥त्वेविश्वातविषीसध्र्यग्घि
ता।तवराधःसोमपीथायहर्षते।तववज्रश्चिकितेबाह्वोर्हितो।वृश्चाशत्रोरवविश्वानिवृष्ण्या
॥विजानीह्यार्यान्येचदस्यवोबर्हिष्मतेरंधयाशासदव्रतान्।शाकीभवयजमानस्यचोदिता
विश्वेत्तातेसधमादेषुचाकन॥अनुव्रतायरंधयन्नपव्रतानाभूभिरिंद्रःश्नथयन्ननाभुवः।
वृद्धस्यचिद्वर्धतोद्यामिनक्षतःस्तवानोवम्रोविजघानसंदिहः॥तक्षद्यत्तेऽउशनासहसा

सं॰अ॰४ सहो'विरोदसीमुज्मनाबाधतेश्शवः।आत्वावातस्य नृमणोमनोयुजुऽ'आपूर्यमाणमवहन्नभिश्रवः

३६ ॥ १० ॥ मंदिष्टयदुशनेकाव्येसचाऽँ'इंद्रोवंकूवंकुतराधितिष्ठति।उग्रोययिंनिरपःस्रोतसासृज'

द्विशुष्णस्य दृंहिताऐरयत्पुरः॥आस्मारथंवृषपाणेषुतिष्ठसि'शार्यातस्यप्रभृतायेषुमंदसि।इं

द्रयथासुतसोमेषुचाकनो' नर्वाणंश्लोकमारोहसेदिवि॥अददाऽअर्भांमहतेवचस्यवे'कक्षी

वतेवृचयामिंद्रसुन्वते।मेनाभवोवृषणश्वस्यसुक्रतो'विश्वेत्तातेसवनेषुप्रवाच्या॥इंद्रोऽअ

श्रायिसुध्योनिरेके'पज्रेषुस्तोमोदुर्योनयूपः।अश्वयुर्गव्यूरथयुर्वसूयु'रिंद्रऽइद्रायःक्षयति

प्रयंता॥इदंनमोवृषभायस्वराजे'सत्यशुष्मायतवसेवाचि।अस्मिन्निंद्रवृजनेसर्ववीराः'स्म

त्सूरिभिस्तवशर्मन्त्स्याम॥ ११ ॥ १५ त्यंसुमेषंमहयास्वर्विदं'शतंयस्यसुभ्वःसाकमीरते। ३६

अत्यंनवाजंहवनस्यदंरथमें'द्रंववृत्यामवसेसुवृक्तिभिः॥सपर्वतोनधरुणेष्वच्युतः'स

हस्रमूतिस्तविषीषु वावृधे। इंद्रो यद्वृत्रमवधीन्नदीवृतं'मुब्जन्नर्णांसि जर्हृषाणोऽअंधसा॥ स
हि द्वरो द्वरिषु वव्रऽऊधनि चंद्रबुध्नो मदवृद्धो मनीषिभिः। इंद्रं तमह्वे स्वपस्यया धिया'मंहिष्ठरातिं
स हि पप्रिरंधसः॥ आ यं पृणंति दिवि सद्मबर्हिषः' समुद्रं न सुभ्वः स्वाऽअभिष्टयः। तं वृत्रहत्येऽ
अनु तस्थुरूतयः' शुष्माऽइंद्रमवाताऽअह्रुतप्सवः॥ अभि स्ववृष्टिं मदेऽअस्य युध्यतो' रघ्वीरिव
प्रवणे सस्रुरूतयः। इंद्रो यद्वज्री धृषमाणोऽअंधसा' भिनद्वलस्य परिधींरिव त्रितः॥ १२ ॥ परीं
घृणा चरति तित्विषे शवो'पो वृत्वी रजसो बुध्नमाशयत्। वृत्रस्य यत्प्रवणे दुर्गृभिश्वनो' निजघंथ
हन्वोरिंद्र तन्यतुं॥ ह्रदं न हि त्वा न्यृषंत्यूर्मयो' ब्रह्माणींद्र तव यानि वर्धना। त्वष्टा चित्ते युज्यं वावृ
धे शवं'स्ततक्ष वज्रमभिभूत्योजसं॥ जघन्वाँऽउ हरिभिः संभृतक्रत'विंद्र वृत्रं मनुषे गातुयन्नपः।
अयच्छथा बाह्वोर्वज्रमायसम'धारयो दिव्या सूर्यं दृशे॥ बृहत्स्वश्चंद्रममवद्यदुक्थ्य१'मकृ

सं·अ·४ ण्वत भियसा रोहणं दिवः। यन्मानुषप्रधना ऽइंद्रमूतयः स्वर्नृषाचो मरुतोमदन्ननु॥ द्यौश्चिदस्याम
३७ वाँ अहेः स्वनादयोयवीद्भियसा वज्र ऽइंद्र ते। वृत्रस्य यद्बद्बधानस्य रोदसी मदे सुतस्य शवसाभि
नच्छिरः॥ १३ ॥ यदिन्न्विंद्र पृथिवी दशभुजिरहानि विश्वा ततनंत कृष्टयः। अत्राह ते मघवन्विश्रु
तं सहो द्यामनु शवसा बर्हणा भुवत॥ त्वमस्य पारे रजसो व्योमनः स्वभूत्योजा ऽअवसे धृषन्मनः।
चकृषे भूमिं प्रतिमानमोजसोपः स्वः परिभूरेष्या दिवं॥ त्वं भुवः प्रतिमानं पृथिव्या ऽऋष्ववीरस्य बृ
हतः पतिर्भूः। विश्वमाप्रा ऽअंतरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान॥ न यस्य द्यावापृथिवी ऽ
अनु व्यचो न सिंधवो रजसो ऽअंतमानशुः। नोत स्ववृष्टिं मदे ऽअस्य युध्यत ऽएको ऽअन्यच्चकृ
षे विश्वमानुषक्॥ आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो ऽअमदन्ननु त्वा। वृत्रस्य यद्भृष्टि ३७
मता वधेन नित्वमिंद्र प्रत्यानं जघंथ॥ १४ ॥ १५ न्यू३ षु वाचं प्र महे भरामहे गिर ऽइंद्राय सद

दने विवस्वतः। नू चिद्धि रत्नं ससतामिवाविदं न दुष्टुतिर्द्रविणोदेषु शस्यते॥ दुरो ऽ अश्वस्य दुरः
इंद्र गोरसि दुरो यवस्य वसुन ऽ इनस्पतिः। शिक्षानरः प्रदिवो ऽ अकामकर्शनः सखा सखिभ्यस्त
मिदं गृणीमसि॥ शचीव ऽ इंद्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु। अतः संगृभ्याभिभू
त ऽ आ भर मा त्वायतो जरितुः काममूनयीः॥ एभिर्द्युभिः सुमना ऽ एभिरिंदुभिर्निरुंधानो ऽ अमतिं
गोभिरश्विना। इंद्रेण दस्युं दरयंत ऽ इंदुभिर्युतद्वेषसः समिषा रभेमहि॥ समिंद्र राया समिषा रभे
महि सं वाजेभिः पुरुश्चंद्रैरभिद्युभिः। सं देव्या प्रमत्या वीरशुष्मया गो ऽ अग्रयाश्वावत्या रभेमहि
॥ २५ ॥ ते त्वा मदा ऽ अमदन्तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते। यत्कारवे दश वृत्राण्यप्र
ति बर्हिष्मते नि सहस्राणि बर्हयः॥ युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा।
नम्या यदिंद्र सख्या परावति निबर्हयो नमुचिं नाम मायिनं। त्वं करंजमुत पर्णयं वधीस्तेजिष्ठ

सं॰अ॰४ यातिथिग्वस्यवर्तनी।त्वंशतावंगृदस्याभिनत्पुरो'नानुदःपरिषूताऽऋजिश्वना॥त्वमेताञ्जनरा
३८ ज्ञोद्विर्दशाबंधुनासुश्रवसोपजग्मुषः।षष्टिंसहस्रानवतिंनवश्रुतो'निचक्रेणरथ्यादुष्पदावृणक्॥
त्वमाविथसुश्रवसंतवोतिभिस्तवत्रामभिरिंद्रतूर्वयाणं।त्वमस्मैकुत्समतिथिग्वमायुं'महेराज्ञे
यूनेऽअरंधनायः॥यऽउदृचींद्रदेवगोपाः'सखायस्तेशिवतमाऽअसाम।त्वांस्तोषामत्वयासुवी
राः'द्राघीयऽआयुःप्रतरंदधानाः॥ १६ ॥ ११ मानोऽअस्मिन्मघवन्पृत्स्वंहसि'नहितेऽअंतःश
वसःपरीणशे।अक्रंदयोनद्योरोरुवद्वना'कथानक्षोणीर्भियसासमारत॥अर्चाशक्रायशाकि
नेशचीवते'शृण्वंतमिंद्रंमहयन्नभिष्टुहि।योधृष्णुनाशवसारोदसीऽउभे'वृषावृषत्वावृष
भोन्यृंजते॥अर्चादिवेबृहतेशूष्यंवचः'स्वक्षत्रंयस्यधृषतोधृषन्मनः।बृहच्छ्रवाऽअसु ३८
रोबर्हणाकृतः'पुरोहरिभ्यांवृषभोरथोहिषः॥त्वंदिवोबृहतःसानुकोपयो'वत्मनाधृषता

शंबरंभिनत्।यन्मायिनोव्रंदिनोमंदिनाधृषच्छितांगभस्तिमशनिंपृतन्यसि॥नियद्वृणक्षिश्व
सनस्यमूर्धनिशुष्णस्यचिद्व्रंदिनोरोरुवद्वना।प्राचीनेनमनसाबर्हणावता।यदद्याचित्कृणवः
कस्त्वापरि॥ १७ ॥त्वमाविथनर्यंतुर्वशंयदुंत्वंतुर्वीतिंवय्यंशतक्रतो।त्वंरथमेतशंकृत्व्येध
नेत्वंपुरोनवतिंदंभयोनव॥सघाराजासत्पतिःशूशुवज्जनोरातहव्यःप्रतियःशासमिन्वति।
उक्थावायोऽभिगृणातिराधसादानुरस्माऽउपरापिन्वतेदिवः॥असमंक्षत्रमसमामनीषा
प्रसोमपाऽअपसासंतुनेमे।येतऽइंद्रददुषोवर्धयंतिमहिक्षत्रंस्थविरंवृष्ण्यंच॥तुभ्येदेतेबहु
लाऽअद्रिदुग्धाश्चमूषदश्चमसाऽइंद्रपानाः।व्यश्नुहितर्पयाकाममेषामथामनोवसुदेयाय
कृष्व॥अपामतिष्ठद्धरुणह्वरंतमोंतर्वृत्रस्यजठरेषुपर्वतः।अभीमिंद्रोनद्योवव्रिणाहितावि
श्वाऽअनुष्ठाःप्रवणेषुजिघ्नते॥सशेवृधमधिधाद्युम्नमस्मेमहिक्षत्रंजनाषाळिंद्रतव्यं।रक्षा

सं·अ·४ चनोमघोनःपाहिसूरीं'स्त्रायेचनःस्वपत्याऽइषेधाः॥ १८ ॥११ दिवश्चिदस्यवरिमाविपप्रथेऽ'
३९ इंद्रंनमह्नापृथिवीचनप्रति।भीमस्तुविष्मांचर्षणिभ्यऽआतपः'शिशीतेवज्रंतेजसेनवंसगः॥
सोऽअर्णवोननद्यःसमुद्रियः'प्रतिगृभ्णातिविश्रितावरीमभिः।इंद्रःसोमस्यपीतयेवृषायते'सना
त्सयुध्मऽओजसापनस्यते॥त्वंतमिंद्रपर्वतंनभोजसे'महोनृम्णस्यधर्मणामिरज्यसि।प्रवीर्ये
णदेवतातिचेकिते'विश्वस्माऽउग्रःकर्मणेपुरोहितः॥सऽइद्वनेनमस्युभिर्वचस्यते'चारुजनेषु
प्रब्रुवाणऽइंद्रियं।वृषाछंदुर्भवतिहर्यतोवृषा'क्षेमेणधेनांमघवायदिन्वति॥सऽइन्महानिस
मिथानिमज्मनाकृणोतियुध्मऽओजसाजनेभ्यः।अधाचनश्रद्दधतित्विषीमतऽ'इंद्रायवज्रं
निघनिघ्नतेवधं॥ १९ ॥सहिश्रवस्युःसदनानिकृत्रिमा'क्ष्मयावृधानऽओजसाविनाशयं ३९
न्।ज्योतींषिकृण्वन्नवृकाणियज्यवे'वसुक्रतुःसर्तवाऽअपःसृजत्॥दानायमनःसोमपा

वन्नस्तुतेऽर्वाञ्चा हरी वंदनश्रुदा कृधि। यमिष्ठासः सारथयो य इंद्र ते न त्वा केता आ दभ्नुवंति भू
र्णयः॥ अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि श्रुतो दधे। आवृतासोवतासो न कर्तृभि
स्तनूषु ते क्रतव इंद्र भूरयः॥ २०॥ ८ एष प्र पूर्वीरव तस्य चम्रिषोऽत्यो न योषामुदयंस्त भुर्व
णिः। दक्षं महे पाययते हिरण्ययं रथमावृत्या हरियोगमृभ्वसं॥ तं गूर्तयो नेमन्निषः परीणसः समु
द्रं न संचरणे सनिष्यवः। पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा॥ स तुर्वणि
र्महाँ अरेणु पौंस्ये गिरेर्भृष्टिर्न भ्राजते तुजा शवः। येन शुष्णं मायिनमायसो मदे दुध्र आभूषु
रामयन्नि दामनि॥ देवी यदि तविषी त्वावृधोतय इंद्रं सिषक्त्युषसं न सूर्यः। यो धृष्णुना शव १७
सा बाधते तम इयर्ति रेणुं बृहदर्हरिष्वणिः॥ वि यत्तिरो धरुणमच्युतं रजोऽतिष्ठिपो दिव आ
तासु बर्हणा। स्वर्मीळ्हे यन्मद इंद्र हर्ष्याहन्वृत्रं निरपामौब्जो अर्णवं॥ त्वं दिवो धरुणं धिषऽ

सं·प्र·४ ओजसापृथिव्याऽइंद्रःसदनेषुमाहिनः।त्वंसुतस्यमदेऽअरिणाऽअपोविवृत्रस्यसमयापाष्यारु
४० जः॥ २१॥ ६ प्रमंहिष्ठायबृहतेबृहद्रयेसत्यशुष्मायतवसेमतिंभरे।अपामिवप्रवणेयस्यदु
र्धरंराधोविश्वायुशवसेऽअपावृतं॥अधतेविश्वमनुहासदिष्टयऽआपोनिम्नेवसवनाहविष्म
तः।यत्पर्वतेनसमशीतहर्यतऽइंद्रस्यवज्रःश्नथिताहिरण्ययः॥अस्मैभीमायनमसासमध्वर
ऽउषोनशुभ्रऽआभरापनीयसे।यस्यधामश्रवसेनामेंद्रियंज्योतिरकारिहरितोनायसे॥इमेतेऽ
इंद्रतेवयंपुरुष्टुतयेत्वारभ्यचरामसिप्रभूवसो।नहित्वदन्योगिर्वणोगिरःसघत्क्षोणीरिवप्रतिनो
हर्यतद्वचः॥भूरितेऽइंद्रवीर्यंतवस्मस्यस्यस्तोतुर्मघवन्काममापृण।अनुतेद्यौर्बृहतीवीर्यं
ममऽइयंचतेपृथिवीनेमऽओजसे॥त्वंतमिंद्रपर्वतंमहामुरुंवज्रेणवज्रिन्पर्वशश्चकर्तिथ। ४०
अवासृजोनिवृताःसर्तवाऽअपःसत्राविश्वंदधिषेकेवलंसहः॥ २२॥ ६ अनुवाकः॥ १०

नूचित्सहोजाऽअमृतोनितुंदते'होतायद्दूतोऽअभवद्विवस्वतः।विसाधिष्ठेभिःपथिभीरजोमम
ऽआदेवताताहविषाविवासति॥आस्वमद्मयुवमानोऽअजरस्तृष्वविष्यन्नतसेषुतिष्ठति।अ
त्योनपृष्ठंप्रुषितस्यरोचते'दिवोनसानुस्तनयन्नचिक्रदत्॥क्राणारुद्रेभिर्वसुभिःपुरोहितो'हो
तानिषत्तोरयिषाळमर्त्यः।रथोनविक्ष्वृंजसानऽआयुषु'व्यानुषग्वार्यादेवऽऋण्वति॥विवात
जूतोऽअतसेषुतिष्ठते'वृथाजुहूभिःसृण्यातुविष्वणिः।तृषुयदग्नेवनिनोवृषायसे'कृष्णंतऽए
मरुशदूर्मेऽअजर॥तपुर्जंभोवनऽआवातचोदितो'यूथेनसाह्वाँऽअववातिवंसगः।अभिव्रज
न्नक्षितंपाजसारजः'स्थातुश्चरथंभयतेपतत्रिणः॥ २३ ॥दधुष्ट्वाभृगवोमानुषेष्वा'रयिंनचारुं
सुहवंजनेभ्यः।होतारमग्नेऽअतिथिंवरेण्यं'मित्रंनशेवंदिव्यायजन्मने॥होतारंसप्तजुह्वोऽय
जिष्ठं'यंवाघतोवृणतेऽअध्वरेषु।अग्निंविश्वेषामरतिंवसूनां'सपर्यामिप्रयसायामिरत्नं॥अच्छि

सं॰ प्र॰ ५ द्रा सूनो सहसो नो ऽअद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ। अग्ने गृणन्तमंहस ऽउरुष्योर्जो नपात्पूर्भिरा
५१ यसीभिः॥ भवा वरूथं गृणते विभावो भवा मघवन्मघवद्भ्यः शर्म। उरुष्याग्ने ऽअंहसो गृणन्तं प्रात
र्मक्षू धियावसुर्जगम्यात्॥ २५ ॥ वया ऽइदग्ने ऽअग्नयस्ते ऽअन्ये त्वे विश्वे ऽअमृता मादयन्ते।
वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनाँ ऽउपमिद्ययन्थ॥ मूर्धा दिवो नाभिरग्निः पृथिव्या ऽअथा
भवदरती रोदस्योः। तं त्वा देवासो ऽजनयन्त देवं वैश्वानर ज्योतिरिदार्याय॥ आ सूर्ये न रश्मयो ध्रुवा
सो वैश्वानरे दधिरे ऽग्ना वसूनि। या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा॥ बृहती ऽइव सू
नवे रोदसी गिरो होता मनुष्यो न दक्षः। स्वर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नृतमाय यह्वीः
॥ दिवश्चित्ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वं। राजा कृष्टीनामसि मानुषीणां युधा दे ५१
वेभ्यो वरिवश्चकर्थ॥ प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते। वैश्वानरो दस्युमग्निर्ज

घृन्वाऽ३ँ'अधूनोत्काष्ठाऽअवशंबरंभेत्॥वैश्वानरोमहिम्नाविश्वकृष्टि'र्भरद्वाजेषुयजतोविभावा।
शातवनेयेशतिनीभिरग्निः'पुरुणीथेजरतेसूनृतावान्॥ २५ ॥ ७ वह्निंयशसंविदथस्यकेतुं'
सुप्राव्यंदूतंसद्योऽअर्थं।द्विजन्मानंरयिमिवप्रशस्तं'रातिंभरद्भृगवेमातरिश्वा॥अस्यशासुरुभया
सःसचंतेहविष्मंतऽउशिजोयेचमर्ताः।दिवश्चित्पूर्वोन्यसादिहोता'ऽऽपृच्छ्योविश्पतिर्विक्षुवेधाः
॥तंनव्यसीहृदऽआजायमानं'मस्मत्सुकीर्तिर्मधुजिह्वमश्याः।यमृत्विजोवृजनेमानुषासः'प्रय
स्वंतऽआयवोजीजनंत॥उशिक्पावकोवसुर्मानुषेषु'वरेण्योहोताधायिविक्षु।दमूनागृहपतिर्द
मऽआँ३'अग्निर्भुवद्रयिपतीरयीणां॥तंत्वावयंपतिमग्नेरयीणां'प्रशंसामोमतिभिर्गोतमासः।
आशुंनवाजंभरंमर्जयंतः'प्रातर्मक्षू॥ २६ ॥ ५ अस्माऽइदुप्रतवसेतुराय'प्रयोनहर्मिस्तोमंमा
हिनाय।ऋचीषमायाध्रिगवऽओह'मिंद्रायब्रह्माणिराततमा॥अस्माऽइदुप्रयऽइवप्रयंसि'भ

सं॰अ॰४ रांम्यांगूषंबाधेसुवृक्ति।इंद्रायहृदामनसामनीषांप्रत्नायपत्येधियोमर्जयंत॥अस्माऽइदुत्यमुप
४२ मंस्वर्षांभरांम्यांगूषमास्येन।मंहिष्ठमच्छोक्तिभिर्मतीनांसुवृक्तिभिःसूरिंवावृधध्यै॥अस्माऽइ
दुस्तोमंसंहिनोमिरथंनतष्टेवतत्सिनाय।गिरश्चगिर्वाहसेसुवृक्तींद्रायविश्वमिन्वंमेधिराय॥अ
स्माऽइदुसप्तिमिवश्रवस्येंद्रायार्कंजुह्वाऽसमंजे।वीरंदानौकसंवंदध्यैपुरांगूर्तश्रवसंदर्माणं
॥ २७ ॥अस्माऽइदुत्वष्टातक्षद्वज्रंस्वपस्तमंस्वर्यंरणाय।वृत्रस्यचिद्विदद्येनमर्मतुजन्नी
शानस्तुजताकियेधाः॥अस्येदुमातुःसवनेषुसद्योमहःपितुंपपिवांचार्वन्ना।मुषायद्विष्णुःप
चतंसहीयान्विध्यद्वराहंतिरोऽअद्रिमस्ता॥अस्माऽइदुग्नाश्चिद्देवपत्नीरिंद्रायार्कमहिहत्यऽ
ऊवुः।परिद्यावापृथिवीजभ्रऽउर्वीनास्यतेमहिमानंपरिष्टः॥अस्येदेवप्ररिरिचेमहित्वंदिवस्पृ ४२
थिव्याःपर्यंतरिक्षात्।स्वराळिंद्रोदमऽआविश्वगूर्तःस्वरिरमत्रोववक्षेरणाय॥अस्येदेवशवसा

शुषंतं विवृश्चद्वज्रेण वृत्रमिंद्रः। गा न व्राणाऽअवनीरमुंचदभि श्रवो दावने सचेताः॥ २८ ॥अस्ये
दु त्वेषसा रंत सिंधवः परि यद्वज्रेण सीमयच्छत्। ईशानकृद्दाशुषे दशस्यन्तुर्वीतये गाधं तुर्व
णिः कः॥ अस्माऽइदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः। गोर्न पर्व वि रदा तिरश्चेष्यन्न
र्णांस्यपां चरध्यै॥ अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्यऽउक्थैः। युधे यदिष्णानऽआयुधा
न्यृघायमाणो निरिणाति शत्रून्॥ अस्येदु भिया गिरयश्च दृह्ळा द्यावा च भूमा जनुषस्तुजेते।
उपो वेनस्य जोगुवानऽओणिं सद्यो भुवद्वीर्याय नोधाः॥ अस्माऽइदु त्यदनु दाय्येषामेको य
द्वव्ने भूरेरीशानः। प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिंद्रः॥ एवा ते हारियोजना सुवृ
क्तींद्र ब्रह्माणि गोतमासोऽअक्रन्। ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू॥ २९ ॥ १६॥ १५॥
१५२ ॥ ०॥ त्वेषसा। रंत। सिंधवः। परि। यत्। वज्रेण। सीं। अयच्छत्। ईशानऽकृत्। दाशुषे। दशस्य

सं॰प्र॰४ नः। तुविरतये। गाधं। तुर्वणिः। कुरितिकुः॥०॥ भुरात्। तुजानः। वृत्राय। वज्रं। ईशानः। किये। धाः। गोः।
४३ ना। पर्वं। विरदात्। तिरश्चा। इष्यन्। अर्णांसि। अपां। चरध्यै॥०॥ प्र। ब्रूहि। पूर्व्याणि। तुरस्य। कर्माणि। न
व्यः। उक्थैः। युधे। यत्। इष्णानः। आयुधानि। ऋघायमाणः। निऽरिणाति। शत्रून्॥०॥ भिया। गिर
यः। च। दृह्ळाः। द्यावा। च। भूम। जनुषः। तुजेते इति। उपो इति। वेनस्य। जोगुवानः। ओणिं। सद्यः।
भुवत्। वीर्याय। नोधाः॥०॥ स्यत्। अनु। दायि। एषां। एकः। यत्। वव्ने। भूरेः। ईशानः। प्र। एतशं। सूर्ये।
पस्पृधानं। सौवश्व्ये। सुस्विं। आवत्। इंद्रः॥ एव। ते। हारिऽयोजना। सुऽवृक्ति। इंद्र। ब्रह्माणि। गोत
मासः। अक्रन्। आ। एषु। विश्वऽपेशसं। धियं। धाः॥०॥ २९ इतिसंहिताप्रथमाष्टके चतुर्थो
ध्यायः॥ ॐ प्रससोनोत्वंनवदृष्णोपंचोनोमारुतंत्रिष्टुबंतंपरमाग्नेयमैंद्रात्यश्वादशाप ४३
राशारःशात्वैयोद्वैपदंतद्रयिर्वैनेषुश्रीणंन्छुकोवनेमैकादशोपप्रदशानिकाव्यारयिर्नोप

+ यामित्यस्यां निपातितो [illegible] नुर [illegible]

दृध्य इ मनुरश्वचेति

प्रयंतो नवं गोतमो राहूगणो गायत्रंतु जुषस्व पंच कातेकथा भिद्वा गायत्रंतु हिरण्यकेशो द्वादशा

×द्यौ तृचौ त्रै ष्टुभौ ब्धि हौ पूर्वो ग्नये वा मध्यमा येत्थाषो ळशैंद्रं पांक्तं हि॥ ५ ॐ प्रमन्महे शव

वसानाय शूषॅ मांगूषं गिर्वणसे ऽअंगिरस्वत्। सुवृक्तिभिस्तुवत ऽऋग्मियायार्चामार्कं नरे विश्रु

ताय॥ प्रवो महे महि नमो भरध्व'मांगूष्यं शवसानाय साम। येना नः पूर्वे पितरः पदज्ञा ऽ'अर्चंतो ऽ

अंगिरसो गा ऽअविंदन्॥ इंद्रस्यांगिरसां चेष्टौ'विदत्सरमा तनयाय धासिं। बृहस्पतिर्भिनदद्रिं वि

दद्गाः समुस्त्रियाभिर्वावशंत नरः॥ ससुष्टुभा सस्तुभा सप्तविप्रैः'स्वरेणाद्रिं स्वर्यो ३ नवग्वैः। सर

ण्युभिः फलिगमिंद्र शक्र'वलं रवेण दरयो दशग्वैः॥ गृणानो ऽअंगिरोभिर्दस्म विवरुषसा सूर्ये

ण गोभिरंधः। विभूम्या ऽअप्रथय ऽइंद्र सानु'दिवो रज ऽउपरमस्तभायः॥ १ तदु प्रयक्षतम

मस्य कर्म'दस्मस्य चारुतममस्ति दंसः। उपह्वरे यदुपरा ऽअपिन्व'न्मध्वर्णसो नद्य १ श्चतस्रः॥

सं·अ·५ द्विताविवव्रेसनजासनीळेऽअयास्यःस्तवमानेभिरर्कैः।भगोनमेनेपरमेव्योमन्'नधारयद्रोद
४४ सीसुदंसाः॥सनाद्दिवंपरिभूमाविरूपे'पुनर्भुवायुवतीस्वेभिरेवैः।कृष्णेभिरक्तोषारुशद्भि'र्वपुर्भि
राचरतोऽअन्यान्या॥सनेमिसख्यंस्वपस्यमानः'सूनुर्दाधारशवसासुदंसाः।आमासुचिद्दधि
षेपक्वमंतः'पयःकृष्णासुरुशद्रोहिणीषु॥सनात्सनीळाऽ [illegible] अवनीरवाता'व्रतारक्षं
तेऽअमृताःसहोभिः।पुरुसहस्राजनयोनपत्नी'र्दुवस्यंतिस्वसारोऽअह्रयाणं॥ २ सनायु
वोनमसानव्योऽअर्कै'र्वसूयवोमतयोदस्मदद्रुः।पतिंनपत्नीरुशतीरुशंतं'स्पृशंतित्वाशव
सावन्मनीषाः॥सनादेवतवरायोगभस्तौ'नक्षीयंतेनोपदस्यंतिदस्म।द्युमाँऽअसिक्रतुमाँ
ऽइंद्रधीरः'शिक्षाशचीवस्तवनःशचीभिः॥सनायतेगोतमऽइंद्रनव्यं'मतक्षद्ब्रह्महरियोज ४४
नायसुनीथायनःशवसाननोधाः'प्रातर्मक्षू०॥ ३ ॥१३ त्वंमहाँऽइंद्रयोहशुष्मै'र्द्यावा

जज्ञानःपृथिवीऽअमेधाः।यद्धंतेविश्वागिरयश्चिदभ्वाभियादृह्ळासःकिरणानैजन्॥आयद्ध
रीऽइंद्रविव्रतावेरातेवज्रंजरिताबाह्वोर्धात्।येनाविहर्यतक्रतोऽअमित्रान्पुरऽइष्णासिपुरुहू
तपूर्वीः॥त्वंसत्यऽइंद्रधृष्णुरेतान्त्वमृभुक्षानर्यस्त्वंषाट्।त्वंशुष्णंवृजनेपृक्षऽआणौयूनेकुत्सा
यद्युमतेसचाहन्॥त्वंहत्यदिंद्रचोदीःसखावृत्रंयद्वज्रिन्वृषकर्मन्नुभ्नाः।यद्धशूरवृषमणःपरा
चैर्विदस्यूँर्योनावकृतोवृथाषाट्॥त्वंहत्यदिंद्रारिषण्यन्दृह्ळस्यचिन्मर्तानामजुष्टौ।व्य१स्मदाका
ष्ठाऽअर्वतेवर्घनेववज्रिञ्छ्नथिह्यमित्रान्॥ ४ त्वांहत्यदिंद्रार्णसातौस्वर्मीह्ळेनरऽआजाह
वंते।तवस्वधावऽइयमासमर्यऽऊतिर्वाजेष्वतसाय्याभूत्॥त्वंहत्यदिंद्रसप्तयुध्यन्पुरोवज्रि
न्पुरुकुत्सायदर्दः।बर्हिर्नयत्सुदासेवृथावर्गंहोराजन्वरिवःपूरवेकः॥त्वंत्यांनऽइंद्रदेवचित्रामि
षमापोनपीपयःपरिज्मन्।ययाशूरप्रत्यस्मभ्यंयंसित्मनमूर्जंनविश्वधक्षरध्यै॥अकारितऽ

सं॰प्र॰५ इन्द्रो गोतमेभिः । ब्रह्माण्योक्ता नमसा हरिभ्यां । सुपेशसं वाजमा भरा नः । प्रातर्मक्षू ॥ ५ । ८ वृ
४५ ष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिं प्र भरा मरुद्भ्यः । अपो न धीरो मनसा सुहस्त्यो गिरः स
मञ्जे विदथेष्वाभुवः ॥ ते जज्ञिरे दिवऽऋष्वास उक्षणो रुद्रस्य मर्याऽअसुराऽअरेपसः । पावका
सः शुचयः सूर्याऽइव सत्वानो न द्रप्सिनो घोरवर्पसः ॥ युवानो रुद्राऽअजराऽअभोग्घनो ववक्षु
रध्रिगावः पर्वताऽइव । दृळ्हा चिद्विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना ॥ चित्रैरञ्जि
भिर्वपुषे व्यञ्जते वक्षःसु रुक्माँऽअधि येतिरे शुभे । अंसेष्वेषां नि मिमृक्षुरृष्टयः साकं जज्ञिरे स्व
धया दिवो नरः ॥ ईशानकृतो धुनयो रिशादसो वातान्विद्युतस्तविषीभिरक्रत । दुहन्त्यूधर्दिव्या
नि धूतयो भूमिं पिन्वन्ति पयसा परिज्रयः ॥ ६ पिन्वन्त्यपो मरुतः सुदानवः पयो घृतवद्विदथे ४५
ष्वाभुवः । अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति स्तनयन्तमक्षितं ॥ महिषासो मायिनश्चित्रभा

नवो'गिरयोनस्वतवसोरघुष्यदः। मृगाऽइवहस्तिनःखादथवना'यदारुणीषुतविषीरयुग्ध्वं॥ सिंहाऽ
इवनानदतिप्रचेतसः'पिशाऽइवसुपिशोविश्ववेदसः। क्षपोजिन्वंतःपृषतीभिर्ऋष्टिभिः'समित्सबा
धःशवसाहिमन्यवः॥ रोदसीऽआवदतागणश्रियो'नृषाचःशूराःशवसाहिमन्यवः। आवंधुरेष्वम
तिर्नदर्शता'विद्युन्नतस्थौमरुतोरथेषुवः॥ विश्ववेदसोरयिभिःसमोकसः'संमिश्लासस्तविषीभिर्विर
प्शिनः। अस्तारऽइषुंदधिरेगभस्त्यो'रनंतशुष्मावृषखादयोनरः॥ ७ हिरण्ययेभिःपविभिःप
योवृधऽउज्जिघ्नंतऽआपथ्यो३नपर्वतान्। मखाऽअयासःस्वसृतोध्रुवच्युतो'दुध्रकृतोमरुतो
भ्राजदृष्टयः॥ घृषुंपावकंवनिनंविचर्षणिं'रुद्रस्यसूनुंहवसागृणीमसि। रजस्तुरंतवसंमारुतं
गणं'मृजीषिणंवृषणंसश्चतश्रिये॥ प्रनूसमर्तःशवसाजनाँऽअति'तस्थौवऽऊतीमरुतोय
मावत। अर्वद्भिर्वाजंभरतेधनानृभि'रापृच्छ्यंक्रतुमाक्षेतिपुष्यति॥ चर्कृत्यंमरुतःपृत्सुदुष्ट

सं॰ प्र॰ १ सं द्युमंतं शुष्मं मघवत्सु धत्तन। धनस्पृतमुक्थ्यं विश्वचर्षणिं'तोकं पुष्येम तनयं शतं हिमाः॥ नू ष्ठि

५६ रं मरुतो वीरवंतमृतीषाहं रयिमस्मासु धत्त। सहस्रिणं शतिनं शूशुवांसं'प्रातमक्षू०॥ ८ ॥१७

अनुवाकः॥ ११ अथ नैमित्तिक द्विपदा॥ पश्वा न तायुं गुहा चतंतं'नमो युजानं नमो वहंतं॥ सजो

षा धीराः पदैरनु ग्म'न्नुप त्वा सीदन्विश्वे यजत्राः॥ ऋतस्य देवाऽअनु व्रता गुर्भुव'त्परिष्टिर्द्यौर्न भू

म॥ वर्धंतीमापः पन्वा सुशिश्वि'मृतस्य योना गर्भे सुजातं॥ पुष्टिर्न रण्वा क्षितिर्न पृथ्वी'गिरिर्न भु

ज्म क्षोदो न शंभु॥ अत्यो नाज्मन्त्सर्गप्रतक्तः'सिंधुर्न क्षोदः कऽईं वराते॥ जामिः सिंधूनां भ्रातेव

स्वस्रा'मिभ्यान्न राजा वनान्यत्ति॥ यद्वातजूतो वना व्यस्था'दग्निर्ह दाति रोमा पृथिव्याः॥ श्वसि

त्यप्सु हंसो न सीद'न्क्रत्वा चेतिष्ठो विशामुषर्भुत्॥ सोमो न वेधाऽऋतप्रजातः'पशुर्न शिश्वा वि ५६

भुर्दूरेभाः॥ ९ ॥१२ रयिर्न चित्रा सूरो न संदृ'गायुर्न प्राणो नित्यो न सूनुः॥ तक्वा न भूर्णिर्वना

सिषक्ति ऽपयो न धेनुः शुचि र्विभावा॥ दाधार क्षेममोको न रण्वो ऽयवो न पक्वो जेता जनानां॥ ऋषि
र्न स्तुभ्वा विक्षु प्रशस्तो ऽवाजी न प्रीतो वयो दधाति॥ दुरोकशोचिः क्रतु र्न नित्यो ऽजायेव योना वरं
विश्वस्मै॥ चित्रो यदभ्राट् श्वेतो न विक्षु ऽरथो न रुक्मी त्वेषः समत्सु॥ सेनेव सृष्टामं दधा ऽत्यस्तु र्न
दिद्यु त्त्वेषप्रतीका॥ यमो ह जातो यमो जनित्वं ऽजारः कनीनां पति र्जनीनां॥ तं वश्चराथा वयं वस
त्या ऽस्तं न गावो नक्षंत इद्धं॥ सिंधु र्न क्षोदः प्र नीचीरैनो ऽन्नवंत गावः स्वर्दृशीके॥ १० व
नेषु जायु र्मर्तेषु मित्रो ऽवृणीते श्रुष्टिं राजेवाजुर्यं॥ क्षेमो न साधुः क्रतु र्न भद्रो ऽभुवत्स्वाधी र्होता हव्य
वाट्॥ हस्ते दधानो नृम्णा विश्वा ऽन्यमे देवान्धाद्गुहा निषीदन्॥ विदंतीमत्र नरो धियंधा हृदा य
त्तष्टान्मंत्राँ अशंसन्॥ अजो न क्षां दाधार पृथिवीं तस्तंभ द्यां मंत्रेभिः सत्यैः॥ प्रिया पदानि प
श्वो नि पाहि ऽविश्वायु रग्ने गुहा गुहं गाः॥ य ऽ ईं चिकेत गुहा भवंत ऽमा यः ससाद धारा मृतस्य॥ वि

सं॰ भ्र॰ ५ ये चृतंत्यृता सपंतऽआ दिद्वसूनि प्रववाचास्मै॥ वि यो वीरुत्सु रोधन्महित्वोत प्रजाऽउत प्रसूष्वंतः
४७ ॥ चित्तिरपां दमे विश्वायुः सद्मेव धीराः संमाय चक्रुः॥ ११ ॥ १० श्रीणन्नुप स्थाद्दिवं भुरण्युः
स्थातुश्चरथमक्तून्व्यूर्णोत्॥ परि यदेषामेको विश्वेषां भुवद्देवो देवानां महित्वा॥ आदित्ते विश्वे
क्रतुं जुषंत शुष्काद्यद्देव जीवो जनिष्ठाः॥ भजंत विश्वे देवत्वं नामऽऋतं सपंतोऽअमृतमेवैः॥ ऋ
तस्य प्रेषाऽऋतस्य धीतिर्विश्वायुर्विश्वेऽअपांसि चक्रुः॥ यस्तुभ्यं दाशाद्यो वा ते शिक्षात्तस्मै चि
कित्वान्रयिं दयस्व॥ होता निषत्तो मनोरपत्ये स चिन्न्वासां पती रयीणां॥ इच्छंत रेतो मिथस्तनू
षु सं जानत स्वैर्दक्षैरमूराः॥ पितुर्न पुत्राः क्रतुं जुषंत श्रोषन्येऽअस्य शासं तुरासः॥ विरायऽ
और्णोद्दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः॥ १२ । १० शुक्रः शुशुक्वाँऽउषो न जारः पप्रा ४७
समीची दिवो न ज्योतिः॥ परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन्॥ वेधाऽअदृप्तोऽ

अग्निर्विजा न न्नूधर्न गोनां स्वाद्मा पितूनां॥ जने न शेवऽ आहूर्यः सन्न्मध्ये निषत्तो रण्वो दुरोणे॥
पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वितारीत्॥ विशो यद्ह्वे नृभिः सनीळाऽ अग्निर्देव
त्वा विश्वान्यश्याः॥ नकिष्टऽ एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टिं चकर्थ॥ तत्तु ते दंसो यदहन्त्स
मानैर्नृभिर्यद्युक्तो विवेरपांसि॥ उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै॥ त्मना वहन्तो दु
रो व्यृण्वन्नवन्त विश्वे स्वर्दृशीके॥ १३ ॥ १० वृनेम पूर्वीरर्यो मनीषाऽ अग्निः सुशोको विश्वा
न्यश्याः॥ आ दैव्यानि व्रता चिकित्वा न मानुषस्य जनस्य जन्म॥ गर्भो योऽ अपां गर्भो वनानां ग
र्भश्च स्थातां गर्भश्चरथां॥ अद्रौ चिदस्माऽ अन्तर्दुरोणे विशां न विश्वोऽ अमृतः स्वाधीः॥ स हि क्ष
पावाँऽ अग्नी रयीणां दाशद्यो ऽअस्माऽ अरं सूक्तैः॥ एता चिकित्वो भूमा नि पाहि देवानां जन्म म
र्ताँश्च विद्वान्॥ वर्धान्यं पूर्वीः क्षपो विरूपाः स्थातुश्च रथमृतप्रवीतं॥ अराधि होता स्वर्निष

सं·प्र·५ त्तः कृण्वन्विश्वान्यपांसि सत्या ॥ गोषु प्रशस्तिं वनेषु धिषे भरंत विश्वे बलिं स्वर्णः ॥ वि त्वा नरः पु
४८ रुत्रा सपर्यन्पितुर्न जिव्रेर्वि वेदो भरंत ॥ इति नेमि त्रिक द्विपदा ॥ अथ नित्य द्विपदा ॥ साधुर्न
गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु ॥ इति नित्य द्विपदा ॥ १७ ॥ ११ उप प्र जिन्वन्नुश
तीरुशंतं पतिं न नित्यं जनयः सनीळाः ॥ स्वसारः श्यावीमरुषीमजुष्रंश्चित्रमुच्छंतीमुषसं न
गावः ॥ वीळु चिद्दृळ्हा पितरो न उक्थैरद्रिं रुजन्नंगिरसो रवेण ॥ चक्रुर्दिवो बृहतो गातुमस्मे
ऽअहः स्वर्विविदुः केतुमुस्राः ॥ दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो३ विभृत्राः ॥ अ
तृष्यंतीरपसो यंत्यच्छा देवान्जन्म प्रयसा वर्धयंतीः ॥ मथीद्यदीं विभृतो मातरिश्वा गृहेगृहे
श्येतो जेन्यो भूत् ॥ आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय ॥ महे यत्पित्र ऽ ईं ४८
रसं दिवे करवत्सरत्पृशन्यश्चिकित्वान् ॥ सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्वि

षिं धात्॥ १५ स्वऽआ यस्तुभ्यं दम॒ऽआ वि॒भा ति॒ नमो॑ वा॒ दाशा॑द्दुश॒तोऽअनु द्यून्। वर्धोऽअग्ने॒
वयोऽअस्य द्वि॒बर्हा॒ यास॒द्राया स॒रथं यं जु॒नासि॥अ॒ग्निं विश्वा॒ऽअ॒भि पृक्षः॑ सचंते॒ समु॒द्रं न स्र॒व
तः स॒प्त य॒ह्वीः। न जा॒मिभि॒र्वि चि॑कि॒ते वयो॑ नो वि॒दा दे॒वेषु॒ प्रम॑तिं चि॒कि॒त्वान्॥आ य॒दिषे॒ नृप॑तिं॒ ते
ज॒ऽआन॒ट् शुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑। अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नं स्वा॒ध्यं ज॑नय॒त्सू॒दय॑च्च॥
मनो॒ न योध्व॑नः स॒द्य एत्येकः॑ स॒त्रा सूरो॒ वस्व॒ऽईशे। राजा॑ना मि॒त्रावरु॑णा सुपा॒णी गोषु॑ प्रि॒यम॒मृतं॒
रक्ष॑माणा॥मा नो॑ऽअग्ने स॒ख्या पि॒त्र्याणि॒ प्रम॑र्षिष्ठा॒ऽअ॒भि वि॒दुष्क॒विः सन्। नभो॒ न रू॒पं ज॑रि॒मा मि
नाति पु॒रा त॒स्याऽअ॒भिश॑स्ते॒रधी॑हि॥ १६। १०। नि काव्या॑ वे॒धसः॒ शश्व॑तस्क॒र्हस्ते॒ दधा॑नो॒ न
र्या पु॒रूणि। अ॒ग्निर्भु॑वद्रयि॒पती॑ र॒यीणां॑ स॒त्रा च॑क्रा॒णोऽअ॒मृता॑नि॒ विश्वा॥अ॒स्मे व॒त्सं परि॒षंतं॒
न विं॑द॒न्निच्छंतो॒ विश्वे॑ऽअ॒मृता॒ऽअमूराः। श्र॒म॒युवः॑ पद॒व्यो॑ धियं॒धास्त॒स्थुः प॒दे प॑र॒मे चार्व॒ग्नेः॥

सं·प्र·५ तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घृतेन शुचयः सपर्यान् । नामानि चिद्दधिरे यज्ञियान्यसूदयंत
४९ तन्वः सुजाताः ॥ आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः । विदन्मर्तो नेमधिता
चिकित्वानग्निं पदे परमे तस्थिवांसं ॥ संजानानाऽउप सीदन्नभिज्ञु पत्नीवंतो नमस्यं नमस्यन् । रि
रिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषि रक्षमाणाः ॥ १७ त्रिः सप्त यद्गुह्यानि त्वेऽइ
त्पदाविदन्निहिता यज्ञियासः । तेभी रक्षंतेऽअमृतं सजोषाः पशूंश्च स्थातॄंश्चरथं च पाहि ॥ विद्वाँ
ऽअग्ने वयुनानि क्षितीनां व्यानुषक्छुरुधो जीवसे धाः । अंतर्विद्वाँऽअध्वनो देवयानानतंद्रो
दूतोऽअभवो हविर्वाट् ॥ स्वाध्यो दिवऽआ सप्त यह्वी रायो दुरो व्यृतज्ञाऽअजानन् । विदद्गव्यं
सरमा दृळ्हमूर्वं येना नु कं मानुषी भोजते विट् ॥ आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासोऽ ४९
अमृतत्वाय गातुं । मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः ॥ अधि श्रियं नि द

धुश्चारुमस्मिं'न्दिवोयद्क्षीऽअमृताऽअकृण्वन्।अधक्षरंतिसिंधवोनसृष्टाः'प्रनीचीरग्नेऽ
अरुषीरजानन्॥ १८ ॥ १० रयिर्नयःपितृवित्तोवयोधाः'सुप्रणीतिश्चिकितुषोनशासुः।
स्योनशीरतिथिर्नप्रीणानो'होतेववसद्मविधतोवितारीत्॥देवोनयःसवितासत्यमन्मा'क्र
त्वोनिपातिवृजनानिविश्वा।पुरुप्रशस्तोऽअमतिर्नसत्यऽ'आत्मेवशेवोदिधिषाय्योभूत्॥दे
वोनयःपृथिवींविश्वधायाऽ'उपक्षेतिहितमित्रोनराजा।पुरःसदःशर्मसदोनवीराऽ'अनवद्या
पतिजुष्टेवनारी॥तंत्वानरोदमऽआनित्यमिद्ध'मग्नेसचंतक्षितिषुध्रुवासु।अधिद्युम्नंनिद
धुर्भूर्यस्मिं'न्भवाविश्वायुर्धरुणोरयीणां॥विपृक्षोऽअग्नेमघवानोऽअश्यु'र्विसूरयोददतो
विश्वमायुः।सनेमवाजंसमिथेष्वर्यो'भागंदेवेषुश्रवसेदधानाः॥ १९ ऋतस्यहिधेनवोवाव
शानाः'स्मदूध्नीःपीपयंतद्युभक्ताः।परावतःसुमतिंभिक्षमाणा'विसिंधवःसमयासस्रुरद्रिं।त्वे

सं·प्र·५ ऽअग्नेसुमतिंभिक्षमाणाः'दिविश्रवोदधिरेयज्ञियासः।नक्ताचचक्रुरुषसाविरूपेकृष्णंचवर्णम
५० रुणंचसंधुः॥यान्रायेमर्तान्सुषूदोऽअग्ने'तेस्याममघवानोवयंच।छायेवविश्वंभुवनंसिसक्ष्या
पप्रिवान्रोदसीऽअंतरिक्षं॥अर्वद्भिरग्नेऽअर्वतोनृभिर्नॄन्'वीरैर्वीरान्वनुयामात्वोताः।ईशाना
सःपितृवित्तस्यरायो'विसूरयःशतहिमानोऽअश्युः॥एतातेऽअग्नऽउचथानिवेधो'जुष्टानि
संतुमनसेहृदेच।शकेमरायःसुधुरोयमंते'धिश्रवोदेवभक्तंदधानाः॥ २० । १० अनुवाकः
१२ उपप्रयंतोऽअध्वरं'मंत्रंवोचेमाग्नये।आरेऽअस्मेचशृण्वते॥यःस्नीहितीषुपूर्व्यः'सं
जग्मानासुकृष्टिषु।अरक्षद्दाशुषेगयं॥उतब्रुवंतुजंतवऽउदग्निर्वृत्रहाजनि।धनंजयोरणे
रणे॥यस्यदूतोऽअसिक्षये'वेषिहव्यानिवीतये।दस्मत्कृणोष्यध्वरं॥तमित्सुहव्यमंगिरः' ५०
सुदेवंसहसोयहो।जनाऽआहुःसुबर्हिषं॥ २१ आचवहासितांऽइह'देवाँउपप्रशस्तये।

हव्यासुश्चंद्रवीतये॥ नयोरुपब्दिरश्व्यः शृण्वेरथस्यकच्चन। यदग्नेयासिदूत्यं॥ त्वोतोवाज्य
ह्रयोऽभिपूर्वस्मादपरः। प्रदाश्वाँऽअग्नेऽअस्थात्॥ उतद्युमत्सुवीर्यं बृहदग्नेविवाससि। देवेभ्यो
देवदाशुषे॥ २२। ९ जुषस्वसप्रथस्तमं वचोदेवप्सरस्तमं। हव्याजुह्वानऽआसनि॥ अथा
तेऽअंगिरस्तमाग्नेवेधस्तमप्रियं। वोचेमब्रह्मसानसि॥ कस्तेजामिर्जनानामग्नेकोदाश्वध्वरः।
कोहकस्मिन्नसिश्रितः॥ त्वंजामिर्जनानामग्नेमित्रोऽअसिप्रियः। सखासखिभ्यऽईड्यः॥ य
जानोमित्रावरुणायजादेवाँऽऋतंबृहत्। अग्नेयक्षिस्वंदमं॥ २३। ५ कातऽउपेतिर्मनसो
वराय भुवदग्नेशंतमाकामनीषा। कोवायज्ञैःपरिदक्षंतऽआप केनवातेमनसादाशेम॥ ए
ह्यग्नऽइहहोतानिषीदादब्धःसुपुरऽएताभवानः। अवतांत्वारोदसीविश्वमिन्वे यजामहेसौ
मनसायदेवान्॥ प्रसुविश्वान्रक्षसोधक्ष्यग्ने भवायज्ञानामभिशस्तिपावा। अथावहसोमप

सं·प्र·५ तिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने ॥ प्रजावता वचसा वह्निरासा ऽऽ चहुवे नि च सत्सीह
५९ देवैः । वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनां ॥ यथा विप्रस्य मनुषो हविर्भिर्दे
वाँ अयजः कविभिः कविः सन् । एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व ॥ २४
५ कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः । यो मर्त्येष्वमृत ऽऋतावा होता यजि
ष्ठ ऽइत्कृणोति देवान् ॥ यो ऽअध्वरेषु शंतम ऽऋतावा होता तमू नमोभिरा कृणुध्वं ॥ अग्निर्यद्वेर्म
र्ताय देवान्त्स चा बोधाति मनसा यजाति ॥ स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः
। तं मेधेषु प्रथमं देवयन्तीर्विश ऽउप ब्रुवते दस्ममारीः ॥ स नो नृणां नृतमो रिशादा ऽअग्निर्गि
रोवसा वेतु धीतिं । तना च ये मघवानः शविष्ठा वाजप्रसूता ऽइषयन्त मन्म ॥ एवाग्निर्गोतमेभि ५९
र्ऋतावा विप्रेभिरस्तोष्ट जातवेदाः । स ऽएषु द्युम्नं पीपयत्स वाजं स पुष्टिं याति जोषमा चिकित्वा

न॥ २५ ॥ ५ अभित्वागोतमागिरा'जातवेदोविचर्षणे। द्युम्नैरभिप्रणोनुमः॥ तमुत्वागोत
मोगिरा'रायस्कामोदुवस्यति। द्युम्नैः०॥ तमुत्वावाजसातमम्'अंगिरस्वद्धवामहे। द्युम्नैः०॥ तमुत्वा
वृत्रहन्तमं'योदस्यूँरवधूनुषे। द्युम्नैः०॥ अवोचामरहूगणाऽअग्नयेमधुमद्वचः। द्युम्नैः०॥ २६
५ हिरण्यकेशोरजसोविसारे' हिर्धुनिर्वातऽइवध्रजीमान्। शुचिभ्राजाऽउषसोनवेदा'य
शस्वतीरपस्युवोनसत्याः॥ आतेसुपर्णाऽअमिनन्तँएवैः'कृष्णोनोनाववृषभोयदीदं। शिवाभिर्न
स्मयमानाभिरागात्पतन्तिमिहःस्तनयन्त्यभ्रा॥ यदीमृतस्यपयसापियानो'नयन्नृतस्यपथिभी
रजिष्ठैः। अर्यमामित्रोवरुणःपरिज्मा'त्वचंपृंचन्त्युपरस्ययोनौ॥ अग्नेवाजस्यगोमतऽईशा
नःसहसोयहो। अस्मेधेहिजातवेदोमहिश्रवः॥ सऽइधानोवसुष्कविरग्निरीळेन्योगिरा। रेव
दस्मभ्यंपुर्वणीकदीदिहि॥ क्षपोराजन्नुतत्मना'ग्नेवस्तोरुतोषसः। सतिग्मजंभरक्षसोदहप्र

सं॰प्र॰५ ति॥ २७ अवानोऽअग्नऽऊतिभि'र्गायत्रस्यप्रभर्मणि।विश्वासुधीषुवंद्य॥आनोऽअग्नेरयिं
५२ भर'सत्रासाहंवरेण्यं।विश्वासुपृत्सुदुष्टरं॥आनोऽअग्नेसुचेतुना'रयिंविश्वायुपोषसं।माडीकं
धेहिजीवसे॥प्रपूतास्तिग्मशोचिषे'वाचोगोतमाग्नये।भरस्वसुम्नयुर्गिरः॥योनोऽअग्नेभिदा
सत्यंतिदूरेपदीष्टसः।अस्माकमिद्वृधेभव॥सहस्राक्षोविचर्षणि'रग्नीरक्षांसिसेधति।होतागृ
णीतऽउक्थ्यः॥ २८ ॥१२ इत्थाहिसोमऽइन्मदे'ब्रह्माचकारवर्धनं।शविष्ठवज्रिन्नोजसा'
पृथिव्यानिःशशाऽअहि'मर्चन्ननुस्वराज्यं॥सत्वामदद्वृषामदः'सोमःश्येनाभृतःसुतः।येना
वृत्रंनिरद्भ्यो'जघंथवज्रिन्नोजसा'र्चन्ननु०॥प्रेह्यभीहिधृष्णुहि'नतेवज्रोनियंसते।इंद्रनृ
म्णंहितेशवो'हनोवृत्रंजयाऽअपो'र्चन्ननु०॥निरिंद्रभूम्याऽअधि'वृत्रंजघंथनिर्दिवः।सृ ५२
जामरुत्वतीरव'जीवधन्याऽइमाऽअपो'र्चन्ननु०॥इंद्रोवृत्रस्यदोधतः'सानुंवज्रेणहीडि

तः। अभिक्रम्यावजिघ्नते ऽपः सर्माय चोदयन्नर्चन्ननु॰॥ २९ अधिसानौ निजिघ्नते वज्रेण शत
पर्वणा। मंदान इंद्रो ऽअंधसः सखिभ्यो गातुमिच्छत्यर्चन्ननु॰॥ इंद्र तुभ्यमिदद्रिवो ऽनुत्तं व
ज्रिन्वीर्यं। यद्ध त्यं मायिनं मृगं तमु त्वं माययावधीरर्चन्ननु॰॥ वि ते वज्रासो ऽअस्थिरन्नवतिं
नाव्या ऽअनु। महत्त ऽइंद्र वीर्यं बाह्वोस्ते बलं हितमर्चन्ननु॰॥ सहस्रं साकमर्चत परिष्टोभत
विंशतिः। शतैनमन्वनोनवुरिंद्राय ब्रह्मोद्यतमर्चन्ननु॰॥ इंद्रो वृत्रस्य तविषीं निरहन्सहसा
सहः। महत्तदस्य पौंस्यं वृत्रं जघन्वाँ असृजदर्चन्ननु॰॥ ३० इमे चित्तव मन्यवे वेपेते भि
यसा मही। यदिंद्र वज्रिन्नोजसा वृत्रं मरुत्वाँ अवधीरर्चन्ननु स्व॰॥ न वेपसा न तन्यतेंद्रं वृ
त्रो वि बीभयत्। अभ्येनं वज्र ऽआयसः सहस्रभृष्टिरायतार्चन्ननु॰॥ यद्वृत्रं तव चाशनिं व
ज्रेण समयोधयः। अहिमिंद्र जिघांसतो दिवि ते बद्बधे शवो ऽर्चन्ननु॰॥ अभिष्टने ते ऽअद्रि

सं·प्र·५ वो॑ यत्स्थाजगच्चरेजते। त्वष्टाचित्तवमन्यवेऽइंद्रवेविज्यतेभियाऽर्चन्ननु०।। नहिनुयादधीमसी॑
५३ इंद्रंकोवीर्यापरः। तस्मिन्नृम्णमुतक्रतुं॑ देवाऽओजांसिसंदधु॑ रर्चन्ननु०।। यामथर्वामनुष्पिता॑ द
ध्यङ्धियमत्नत। तस्मिन्ब्रह्माणिपूर्वथें॑ द्रऽउक्थासमग्मता॑ र्चन्ननु०।। ३१ । १६।११।
१८५।। इमे इति। चित्। तव। मन्यवे। वेपेते इति। भियसा। मही इति। यत्। इंद्र। वज्रिन्। ओजसा।
वृत्रं। मरुत्वान्। अवधीः। ० न। वेपसा। न। तन्यता। इंद्रं। वृत्रः। वि। बीभयत्। अभि। एनं। वज्रः।
आयसः। सहस्रऽभृष्टिः। आयत। ० यत्। वृत्रं। तव। च। अशनिं। वज्रेण। सम्ऽअयोधयः। अ
हिं। इंद्र। जिघांसतः। दिवि। ते। बद्बधे। शवः। ० अभिऽस्तने। ते। अद्रिऽवः। यत्। स्थाः। जगत्।
च। रेजते। त्वष्टा। चित्। तव। मन्यवे। इंद्र। वेविज्यते। भिया। ० नहि। नु। यात्। अधिऽइमसि। इं ५३
द्रं। कः। वीर्या। परः। तस्मिन्। नृम्णं। उत। क्रतुं। देवाः। ओजांसि। सं। दधुः। ० यां। अथर्वा। मनुः।

पिता। दध्यङ्। धियं। अत्नत। तस्मिन्। ब्रह्माणि। पूर्वऽथा। इंद्रे। उक्था। सं। अग्मत। ०॥ ३१ ।
इति संहितायां प्रथमाष्टके पंचमोऽध्यायः। ॐ ॥ इंद्रो नवोपोषुषड् जगत्यं तमश्वा
वति जागतमसावि विंशतिः षळनुष्टुभं ओष्णिहपाद्भ गायत्रत्रैष्टुभास्तृचौः प्रगाथः प्रयेद्वादश
मारुतं ह पंचम्यं त्ये त्रिष्टुभौ मरुतो दश गायत्रं प्रत्वक्षसः षड्जागतमाविद्युन्म द्विराद्यां त्ये प्रस्ता
र पङ्क्तीं पंचमी विराड्रूपाऽऽनो दश वैदेवं तु पंचाद्याः सप्तमी च जगत्यः षष्ठी विराट्स्थानं ऋजुनी
ती नव गायत्रं मंत्यानुष्टुप् त्वं सोम न्यधिका सौम्यं पंचम्यादि गायत्र्यो द्वादशोष्णिक्के ता उत्या इन्द्र
नोषस्यं चतुर्जगत्यादिष ळुष्णिगंतं तृचोंत्य आश्विनोऽग्नीषोमो द्वादशाग्नीषोमीयं मा द्यास्ति
स्रोनुष्टुभं उपांत्यास्तिस्रो गायत्र्यो ष्टमी जगती वेमं षोळश कुत्स आग्नेयं तद्धि त्रिष्टुबं तं पूर्वो दे
वास्त्रयः पादादेर्वास्तन्नो मित्रोर्धर्चौ लिंगोक्तदैवतो यद्वैवत्यं वा सूक्तं ॥ ६ । ॐ । इंद्रो मदा

सं·प्र·६ यवावृधे'शवसेवृत्रहानृभिः।तमिन्महत्स्वाजिषूतेमर्भेहवामहेसवाजेषुप्रनोविषत्॥असिहि
५४ वीरसेन्यो'सिभूरिपराददिः।असिदभ्रस्यचिद्वृधो'यजमानायशिक्षसि'सुन्वतेभूरितेवसु॥
यदुदीरतऽआजयो'धृष्णवेधीयतेधना।युक्ष्वामदच्युताहरी'कंहनःकंवसौदधो'स्माँऽइंद्र
वसौदधः॥क्रत्वामहाँऽअनुष्वधं'भीमऽआवावृधेशवः।श्रियऽऋष्वऽउपाकयो'र्निशिप्रीह
रिवान्दधेहस्तयोर्वज्रमायसं॥आपप्रौपार्थिवंरजो'बद्बधेरोचनादिवि।नत्वावाँऽइंद्रकश्च धे
न'नजातोनजनिष्यते'तिविश्वंववक्षिथ॥ १ योऽअर्योमर्तभोजनं'पराददातिदाशुषे।
इंद्रोऽअस्मभ्यंशिक्षतु'विभजाभूरितेवसु'भक्षीयतवराधसः॥मदेमदेहिनोददि'र्यूथाग
वामृजुक्रतुः।संगृभायपुरूशतो'भयाहस्त्यावसु'शिशीहिरायऽआभर॥मादयस्वसुतेसचा' ५४
शवसेशूरराधसे।विद्माहित्वापुरूवसुमुपकामान्ससृज्महे'थानोविताभव॥एतेतऽइंद्र

ज्ञंतवो'विश्वंपुष्यंतिवार्यं।अंतर्हिख्योजनाना'मर्योवेदोऽअदाशुषां'तेषांनोवेदऽआभर॥ २
७ उपोषुश्रृणुहीगिरो'मघवन्मातथाऽइव।यदानःसूनृतावतः'करऽआदर्थयासऽइद्'यो
जान्विंद्रतेहरी॥अक्षन्नमीमदंतह्यवप्रियाऽअधूषत।अस्तोषतस्वभानवो'विप्रानविष्ठया
मती'योजा०॥सुसंदृशंत्वावयं'मघवन्वंदिषीमहि।प्रनूनंपूर्णवंधुरः'स्तुतोयाहिवशाँऽअनु'
योजा०॥सघात्वंवृषणंरथ'मधितिष्ठातिगोविदं।यःपात्रंहारियोजनं'पूर्णमिंद्रचिकेतति'यो
जा०॥युक्तस्तेऽअस्तुदक्षिणऽ'उतसव्यःशतक्रतो।तेनजायामुपप्रियां'मंदानोयाह्यंधसो'यो
जा०॥युनज्मितेब्रह्मणाकेशिनाहरीऽउपप्रयाहिदधिषेगभस्त्योः।उत्वासुतासोरभसाऽअमं
दिषुः'पूषण्वान्वज्रिन्त्समुपत्न्यामदः॥ ३ । अश्वावतिप्रथमोगोषुगच्छति'सुप्रावी
रिंद्रमर्त्यस्तवोतिभिः।तमित्पृणक्षिवसुनाभवीयसा'सिंधुमापोयथाभितोविचेतसः॥आ

सं॰प्र॰६ पोनदेवीरुपयंतिहोत्रियंमवःपश्यंतिविततंयथारजः।प्राचैर्देवासःप्रणयंतिदेवयुंब्रह्मप्रियं
५५ जोषयंतेवराऽइव॥अधिद्वयोरदधाऽउक्थ्यंवचोयतस्रुचामिथुनायासपर्यतः।असंय
त्तोव्रतेतेक्षेतिपुष्यतिभद्राशक्तिर्यजमानायसुन्वते॥आदंगिराःप्रथमंदधिरेवयऽइद्धाग्नयः
शम्यायेसुकृत्यया।सर्वंपणेःसमविंदंतभोजनमश्वावंतंगोमंतमापशुंनरः॥यज्ञैरथर्वाप्रथ
मःपथस्ततेततःसूर्योव्रतपावेनऽआजनि।आगाऽआजदुशनाकाव्यःसचायमस्यजातम
मृतंयजामहे॥बर्हिर्वायत्स्वपत्यायवृज्यतेर्कोवाश्लोकमाघोषतेदिवि।ग्रावायत्रवदतिका
रुरुक्थ्यस्तस्येदिंद्रोऽअभिपित्वेषुरण्यति॥ ४ । ६ असाविसोमऽइंद्रतेशविष्ठधृष्ण
वागहि।आत्वापृणक्त्विंद्रियंरजःसूर्योनरश्मिभिः॥इंद्रमिद्धरीवहतोप्रतिधृष्टशवसं।ऋ ५५
षीणांचस्तुतीरुपयज्ञंचमानुषाणां॥आतिष्ठवृत्रहन्रथंयुक्तातेब्रह्मणाहरी।अर्वाची

नं सुते मनो 'ग्रावा कृणोतु वग्नुना ॥ इममिंद्र सुतं पिब 'ज्येष्ठममर्त्यं मदं । शुक्रस्य त्वाभ्यक्षर'न्धाराऽ
ऋतस्य सादने ॥ इंद्राय नूनमर्चतो 'क्थानि च ब्रवीतन । सुता ऽअमत्सुरिंदवो 'ज्येष्ठं नमस्यता सहः ॥
५ नकिष्ट्वद्रथीतरो 'हरी यदिंद्र यच्छसे । नकिष्ट्वानु मज्मना 'नकिः स्वश्व ऽआनशे ॥ य ऽएक ऽइद्वि
दयते 'वसु मर्ताय दाशुषे । ईशानो ऽअप्रतिष्कुत ऽइंद्रो ऽअंग ॥ कदा मर्तमराधसं 'पदा क्षुंपमिव
स्फुरत् । कदा नः शुश्रवद्गिर ऽइंद्रो ऽअंग ॥ यश्चिद्धि त्वा बहुभ्य ऽआ 'सुतावाँ ऽआविवासति । उग्रं
तत्पत्यते शव ऽइंद्रो ऽअंग ॥ स्वादोरित्था विषूवतो 'मध्वः पिबंति गौर्यः । या ऽइंद्रेण सयावरी 'र्वृष्णा
मदंति शोभसे 'वस्वीरनु स्वराज्यं ॥ ६ ता ऽअस्य पृशनायुवः 'सोमं श्रीणंति पृश्नयः । प्रिया ऽइंद्र
स्य धेनवो 'वज्रं हिन्वंति सायकं 'वस्वीः ॥ ता ऽअस्य नमसा सहः 'सपर्यंति प्रचेतसः । व्रतान्यस्य
सश्चिरे 'पुरूणि पूर्वचित्तये 'वस्वीः ॥ इंद्रो दधीचो ऽअस्थभिर्वृत्राण्यप्रतिष्कुतः । जघान नव

सं·प्र·६ तीर्नव॥ इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितं। तद्विदच्छर्यणावति॥ अत्राह गोरमन्वत ना
५६ म त्वष्टुरपीच्यं। इत्था चंद्रमसो गृहे॥ ७ कोऽअद्य युंक्ते धुरि गाऽऋतस्य शिमीवतो भामिनो
दुर्हृणायून्। आसन्निषून्हृत्स्वसो मयोभून्य ऽएषां भृत्यामृणधत्स जीवात्॥ कऽईषते तुज्य
ते को बिभाय को मंसते संतमिंद्रं कोऽअंति। कस्तोकाय कऽइभायोत राये ऽधि ब्रवत्तन्वे ३ को ज
नाय॥ कोऽअग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऽऋतुभिर्ध्रुवेभिः। कस्मै देवाऽआवहानाशु
होम को मंसते वीतिहोत्रः सुदेवः॥ त्वमंग प्रशंसिषो देवः शविष्ठ मर्त्यं। न त्वदन्यो मघवन्न × तु ५
स्ति मर्डितेंद्र ब्रवीमि ते वचः॥ मा ते राधांसि मा तऽऊतयो वसो ऽस्मान्कदा चना दभन्। विश्वा
च नऽउपमिमीहि मानुष वसूनि चर्षणिभ्युऽआ॥ ८ । २० अनुवाकः। १३ प्र ये शुंभंते ज ५६
नयो न सप्तयो यामन्रुद्रस्य सूनवः सुदंससः। रोदसी हि मरुतश्चक्रिरे वृधे मदंति वीरा वि

रथेषु घृष्वयः॥ तेऽउक्षितासो महिमानमाशत दिवि रुद्रासोऽअधि चक्रिरे सदः। अर्चंतोऽअर्कं ज
नयंतऽइंद्रियमधि श्रियो दधिरे पृश्निमातरः॥ गोमातरो यच्छुभयंतेऽअंजिभिस्तनूषु शुभ्रा
दधिरे विरुक्मतः। बाधंते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घृतं॥ वि ये भ्राजंते सुमखा
सऽऋष्टिभिः प्रच्यावयंतोऽअच्युता चिदोजसा। मनोजुवो यन्मरुतो रथेष्वा वृषव्रातासः पृषती
रयुग्ध्वं॥ प्र यद्रथेषु पृषतीरयुग्ध्वं वाजेऽअद्रिं मरुतो रंहयंतः। उतारुषस्य वि ष्यंति धाराश्चर्मे
वोदभिर्व्युंदंति भूम॥ आ वो वहंतु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः। सीदता बर्हि
रुरु वः सदस्कृतं मादयध्वं मरुतो मध्वोऽअंधसः॥ १ तेऽवर्धंत स्वतवसो महित्वना नाकं
तस्थुरुरु चक्रिरे सदः। विष्णुर्यद्धावद्वृषणं मदच्युतं वयो न सीदन्नधि बर्हिषि प्रिये॥ शूराऽइ
वेद्युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे। भयंते विश्वा भुवना मरुद्भ्यो राजानऽइ

मं·प्र·६ वत्वेषसंदृशोनरः॥त्वष्टायद्वज्रंसुकृतंहिरण्ययं'सहस्रभृष्टिंस्वपाऽअवर्तयत।धत्तऽइंद्रोनर्यपां
५७ सिकर्तवे'हन्वृत्रंनिरपामौब्जदर्णवं॥ऊर्ध्वंनुनुद्रेऽवतंतऽओजसा'दादृहाणंचिद्बिभिदुर्विपर्वतं।
धमंतोवाणंमरुतःसुदानवो'मदेसोमस्यरण्यानिचक्रिरे॥जिह्मंनुनुद्रेऽवतंतयादिशा'सिंचन्नु
त्संगोतमायतृष्णजे।आगच्छंतीमवसाचित्रभानवः'कामंविप्रस्यतर्पयंतधामभिः॥यावःशर्म
शशमानायसंति'त्रिधातूनिदाशुषेयच्छताधि।अस्मभ्यंतानिमरुतोवियंत'रयिंनोधत्तवृष
णःसुवीरं॥ १० । १२ मरुतोयस्यहिक्षये'पाथादिवोविमहसः।ससुगोपातमोजनः॥यज्ञै
र्वायज्ञवाहसो'विप्रस्यवामतीनां।मरुतःशृणुताहवं॥उतवायस्यवाजिनो'ऽनुविप्रमतक्षत।स
गंतागोमतिव्रजे॥अस्यवीरस्यबर्हिषि'सुतःसोमोदिविष्टिषु।उक्थंमदश्चशस्यते॥अस्यश्रो ५७
षंत्वाभुवो'विश्वायश्चर्षणीरभि।सूरंचित्सस्रुषीरिषः॥ ११ पूर्वीभिर्हिददाशिम'शरद्भि

मरुतो वयं।अवोभिश्चर्षणीनां॥सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः।यस्य प्रयांसि पर्षथ॥श
शमानस्य वा नरः स्वेदस्य सत्यशवसः।विदा कामस्य वेनतः॥यूयं तत्सत्यशवस आविष्कर्त
महित्वना।विध्यता विद्युता रक्षः॥गूहता गुह्यं तमो वियात विश्वमत्रिणं।ज्योतिष्कर्ता यदुश्मसि
॥ १२ । १० प्रत्वक्षसः प्रतवसो विरप्शिनो नानता अविथुरा ऋजीषिणः।जुष्टतमासो नृतमा
सो अंजिभिर्व्यानज्रे के चिदुस्रा इव स्तृभिः॥उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चि
त्पथा।श्चोतंति कोशा उप वो रथेष्वा घृतमुक्षता मधुवर्णमर्चते॥प्रैषामज्मेषु विथुरेव रेजते भू
मिर्यामेषु यद्ध युंजते शुभे।ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयं महित्वं पनयंत धूतयः॥स हि स्व
सृत्पृषदश्वो युवा गणो३ या ईशानस्तविषीभिरावृतः।असि सत्य ऋणयावानेद्यो ऽस्या धियः
प्राविताथा वृषा गणः॥पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्रजिगाति चक्षसा।यदीमिं

सं·प्र·६ द्रंशम्यृक्वाणऽआशता'दिन्नामानियज्ञियानिदधिरे॥श्रियसेकंभानुभिःसंमिमिक्षिरे'तेरश्मि
५८ भिस्तऽऋक्वभिःसुखादयः।तेवाशीमंतऽइष्मिणोऽअभीरवो'विद्रेप्रियस्यमारुतस्यधाम्नः॥
१२ । ६ आविद्युन्मद्भिर्मरुतःस्वर्कैः'रथेभिर्यातऽऋष्टिमद्भिरश्वपर्णैः।आवर्षिष्ठयानऽइषा'
वयोनपप्तता सुमायाः॥तेरुणेभिर्वरमापिशंगैः'शुभेकंयांतिरथतूर्भिरश्वैः।रुक्मोनचित्रःस्वधि
तीवा'न्पव्यारथस्यजंघनंतभूम॥श्रियेकंवोऽअधितनूषुवाशी'र्मेधावनानकृणवंतऽऊर्ध्वा॥यु
ष्मभ्यंकंमरुतःसुजाता'स्तुविद्युम्नासोधनयंतेऽअद्रिं॥अहानिगृध्राःपर्यावऽआगु'रिमांधि
यंवार्कार्यांचदेवीं।ब्रह्मकृण्वंतोगोतमासोऽअर्कै'रूर्ध्वंनुनुद्रऽउत्सधिंपिबध्यै॥एतत्त्यन्नयो
जनमचेति'सस्वर्हयन्मरुतोगोतमोवः।पश्यन्हिरण्यचक्रानयोदंष्ट्रा'न्विधावतोवराहून्॥एषा ५८
स्यावोमरुतोनुभर्त्री'प्रतिष्टोभतिवाघतोनवाणी।अस्तोभयद्वृथासा'मनुस्वधांगभस्त्योः॥ १४

६ आनोभद्राःक्रतवोयंतुविश्वतो'दब्धासोऽअपरीतासऽउद्भिदः।देवानोयथासदमिद्वृधेऽ
असन्नप्रायुवोरक्षितारोदिवेदिवे॥देवानांभद्रासुमतिर्ऋजूयतां'देवानांरातिरभिनोनिवर्त्ततां।दे
वानांसख्यमुपसेदिमावयं'देवानऽआयुःप्रतिरंतुजीवसे॥तान्पूर्वयानिविदाहूमहेवयं'भगंमि
त्रमदितिंदक्षमस्रिधं।अर्यमणंवरुणंसोममश्विना'सरस्वतीनःसुभगामयस्करत्॥तन्नोवा
तोमयोभुवातुभेषजं'तन्मातापृथिवीतत्पिताद्यौः।तद्ग्रावाणःसोमसुतोमयोभुवस्तदश्विना
शृणुतंधिष्ण्यायुवं॥तमीशानंजगतस्तस्थुषस्पतिं'धियंजिन्वमवसेहूमहेवयं।पूषानोयथा
वेदसामसद्वृधे'रक्षितापायुरदब्धःस्वस्तये॥ १५ स्वस्तिनऽइंद्रोवृद्धश्रवाः'स्वस्तिनःपूषावि
श्ववेदाः।स्वस्तिनस्तार्क्ष्योऽअरिष्टनेमिः'स्वस्तिनोबृहस्पतिर्दधातु॥पृषदश्वामरुतःपृश्निमात
रः'शुभंयावानोविदथेषुजग्मयः।अग्निर्जिह्वामनवःसूरचक्षसो'विश्वेनोदेवाऽअवसागम

सं॰प्र॰६ न्निह॥भद्रंकर्णेभिःशृणुयामदेवा' भद्रंपश्येमाक्षभिर्यजत्राः। स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेम
५९ देवहितंयदायुः॥शतमिन्नुशरदोऽअंतिदेवा'यत्रानश्चक्राजरसंतनूनां। पुत्रासोयत्रपितरो
भवंति'मानोमध्यारीरिषतायुर्गंतोः॥अदितिर्द्यौरदितिरंतरिक्ष'मदितिर्माता सपितासपुत्रः।
विश्वेदेवाऽअदितिःपंचजनाऽअदितिर्जातमदितिर्जनित्वं॥ १६ । १॰ ऋजुनीतीनोवरुणो'
मित्रोनयतुविद्वान्। अर्यमादेवैःसजोषाः॥तेहिवस्वोवसवाना'स्तेऽअप्रमूरामहोभिः। व्रता
रक्षंतेविश्वाहा॥तेऽअस्मभ्यंशर्मयंस'न्नमृतामर्त्येभ्यः। बाधमानाऽअपद्विषः॥विनःपथः
सुवितायचियंत्विंद्रोमरुतः। पूषाभगोवंद्यासः॥उतनोधियोगोऽअग्राः'पूषन्विष्णवेवया
वः। करर्तानःस्वस्तिमतः॥ १७ मधुवाताऽऋतायते'मधुक्षरंतिसिंधवः। माध्वीर्नःसंत्वोष ५९
धीः॥मधुनक्तमुतोषसो'मधुमत्पार्थिवंरजः। मधुद्यौरस्तुनःपिता॥मधुमान्नोवनस्पति'

र्मधुमाँ अस्तु सूर्यः।माध्वीर्गावो भवंतु नः॥शंनो मित्रः शंवरुणः'शंनो भवत्वर्यमा।शंन ऽ इंद्रो बृ
हस्पतिः'शंनो विष्णुरुरुक्रमः॥ १८ । त्वंसोम प्रचिकितो मनीषा'त्वंरजिष्ठमनु नेषि पंथां
।तव प्रणीती पितरो न ऽ इंदो' देवेषु रत्नमभजंत धीराः॥त्वंसोम क्रतुभिः सुक्रतुर्भूः'त्वंदक्षैः सु
दक्षो विश्ववेदाः।त्वंवृषा वृषत्वेभिर्महित्वा'द्युम्नेभिर्द्युम्न्यभवो नृचक्षाः॥राज्ञो नु ते वरुणस्य
व्रतानि'बृहद्गभीरंतव सोम धाम।शुचिष्ट्वमसि प्रियो न मित्रो'दक्षाय्यो ऽ अर्यमेवासि सोम॥
या ते धामानि दिवि या पृथिव्यां'या पर्वतेष्वोषधीष्वप्सु।तेभिर्नो विश्वैः सुमना ऽ अहेळ'न्राजन्त्सो
म प्रति हव्या गृभाय॥त्वंसोमासि सत्पतिं स्त्वंराजोत वृत्रहा।त्वंभद्रो ऽ असि क्रतुः॥ १९ त्वंचसो
मनो वशो'जीवातुं न मरामहे।प्रियस्तोत्रो वनस्पतिः॥त्वंसोम महे भगं'त्वंयून ऽ ऋतायते।द
क्षंदधासि जीवसे॥त्वंनः सोम विश्वतो'रक्षा राजन्नघायतः।न रिष्येत्वावतः सखा॥सोमया

सं॰प्र॰६ स्तोम मयोभुवऽऊतयः संनिदाशुषे । ताभिर्नोविता भव ॥ इमं यज्ञमिदं वचोजुजुषाणऽउपागहि
६० । सोम त्वं नो वृधे भव ॥ २० सोम गीर्भिष्ट्वा वयं वर्धयामो वचोविदः । सुमृळीको नऽआविश ॥
गयस्फानोऽअमीवहा वसुवित्पुष्टिवर्धनः । सुमित्रः सोम नो भव ॥ सोम रारन्धि नो हृदि गावो न
यवसेष्वा । मर्यऽइव स्वऽओक्ये ॥ यः सोम सख्ये तव रारणद्देव मर्त्यः । तं दक्षः सचते कविः ॥
उरुष्याणोऽअभिशस्तेः सोम निपाह्यंहसः । सखा सुशेवऽएधि नः ॥ २१ आप्यायस्व समेतु
ते विश्वतः सोम वृष्ण्यं । भवा वाजस्य संगथे ॥ आप्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः । भवा
नः सुश्रवस्तमः सखा वृधे ॥ सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः । आप्याय
मानोऽअमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ॥ या ते धामानि हविषा यजन्ति ता ते विश्वा ६०
परिभूरस्तु यज्ञं । गयस्फानः प्रतरणः सुवीरोऽवीरहा प्रचरा सोम दुर्यान् ॥ सोमो धेनुं सोमोऽ

अर्वंतमाशुं'सोमोवीरंकर्मण्यंददाति।सादन्यंविदथ्यंसभेयं'पितृश्रवणंयोददाशदस्मै॥ २२
अषाळ्हंयुत्सुपृतनासुपप्रिं'स्वर्षामप्सांवृजनस्यगोपां।भरेषुजांसुक्षितिंसुश्रवसं'जयंतंत्वाम
नुमदेमसोम॥त्वमिमाऽओषधीःसोमविश्वा'स्त्वमपोऽअजनयस्त्वंगाः।त्वमाततंथोर्वं१तरि
क्षं'त्वंज्योतिषावितमोववर्थ॥देवेननोमनसादेवसोम'रायोभागंसहसावन्नभियुध्य।मात्वात
नदीशिषेवीर्यस्यो'भयेभ्यःप्रचिकित्सागविष्टौ॥ २३ ।२३ एताऽउत्याऽउषसःकेतुमक्रत'पूर्वेऽ
अर्धेरजसोभानुमंजते।निष्कृण्वानाऽआयुधानीवधृष्णवः'प्रतिगावोरुषीर्यंतिमातरः॥उद
पप्तन्नरुणाभानवोवृथा'स्वायुजोऽअरुषीर्गाऽअयुक्षत।अक्रन्नुषासोवयुनानिपूर्वथा'रुशं
तंभानुमरुषीरशिश्रयुः॥अर्चंतिनारीरपसोनविष्टिभिः'समानेनयोजनेनापरावतः।इषंव
हंतीःसुकृतेसुदानवे'विश्वेदहयजमानायसुन्वते॥अधिपेशांसिवपतेनृतूरि'वापोर्णुतेवक्षऽ

सं॰प्र॰६ उस्रेव बर्जहं। ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्युषा आवर्तमः॥ प्रत्यर्ची रुशदस्या
६१ अदर्शि वितिष्ठते बाधते कृष्णमभ्वं। स्वरुं न पेशो विदथेष्वंजं चित्रं दिवो दुहिता भानुमश्रेत्॥
२४ अतारिष्म तमसस्पारमस्योषा उच्छंती वयुना कृणोति। श्रिये छंदो न स्मयते विभाती सु
प्रतीका सौमनसायाजीगः॥ भास्वती नेत्री सूनृतानां दिवः स्तवे दुहिता गोतमेभिः। प्रजावतो नृव
तो अश्वबुध्यानुषो गोअग्राँ उप मासि वाजान्॥ उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयि
मश्वबुध्यं। सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहंतं॥ विश्वानि देवी भुवनाभिच
क्ष्या प्रतीची चक्षुरुर्विया वि भाति। विश्वं जीवं चरसे बोधयंती विश्वस्य वाचमविदन्मनायोः॥
पुनः पुनर्जायमाना पुराणी समानं वर्णमभि शुंभमाना। श्वघ्नीव कृत्नुर्विज आमिनाना मर्त ६१
स्य देवी जरयंत्यायुः॥ २५ व्यूर्ण्वती दिवो अंताँ अबोध्यप स्वसारं सनुतर्युयोति। प्रमि

नती मनुष्या युगानि योषा जारस्य चक्षसा विभाति॥ पशून्न चित्रा सुभगा प्रथाना सिंधुर्न क्षोद ऽ
उर्विया व्यश्वैत्। अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना॥ उषस्तच्चित्रमा भरास्म
भ्यं वाजिनीवति। येन तोकं च तनयं च धामहे॥ उषोऽअद्येह गोमत्यश्वावति विभावरि। रेवदस्मे
व्युच्छ सूनृतावति॥ युक्ष्वा हि वाजिनीवत्यश्वाँ अद्यारुणाँ उषः। अथा नो विश्वा सौभगान्या व
ह॥ २६ अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत्। अर्वाग्रथं समनसा नि यच्छतं॥ यावित्था
श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः। आ नऽऊर्जं वहतमश्विना युवं॥ एह देवा मयोभुवा दस्रा हि
रण्यवर्तनी। उषर्बुधो वहंतु सोमपीतये॥ २७ ।१८ अग्नीषोमाविमं सु मे शृणुतं वृषणा हवं।
प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः॥ अग्नीषोमा योऽअद्य वामिदं वचः सपर्यति। तस्मै ध
त्तं सुवीर्यं गवां पोषं स्वश्व्यं॥ अग्नीषोमा यऽआहुतिं यो वां दाशाद्धविष्कृतिं। स प्रजया सुवी

सं.क्र.६ र्यं 'विश्वमायुर्व्यश्नवत्॥ अग्नीषोमा चेति तद्वीर्यं वां 'यदमुष्णीतमवसं पणिं गाः। अवातिरतं बृ
६२ सयस्य शेषो 'विंदतं ज्योतिरेकं बहुभ्यः॥ युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू ऽअ
धत्तं। युवं सिंधूंरभिशस्तेरवद्याद्'ग्नीषोमावमुंचतं गृभीतान्॥ आन्यं दिवो मातरिश्वा जभारा
मथ्नादन्यं परि श्येनो ऽअद्रेः। अग्नीषोमा ब्रह्मणा वावृधानो'रुं यज्ञाय चक्रथुरु लोकं॥ २९
अग्नीषोमा हविषः प्रस्थितस्य 'वीतं हर्यतं वृषणा जुषेथां। सुशर्माणा स्ववसा हि भूतमथा धत्तं
यजमानाय शं योः॥ यो ऽअग्नीषोमा हविषा सपर्याद्' देवद्रीचा मनसा यो घृतेन। तस्य व्रतं र
क्षतं पातमंहसो 'विशे जनाय महि शर्म यच्छतं॥ अग्नीषोमा सवेदसा 'सहूती वनतं गिरः। सं
देवत्रा बभूवथुः॥ अग्नीषोमावनेन वां 'यो वां घृतेन दाशति। तस्मै दीदयतं बृहत्॥ अग्नीषो ६२
माविमानि नो 'युवं हव्या जुजोषतं। आ यातमुप नः सचा॥ अग्नीषोमा पिपृतमर्वतो न ऽआ प्या

यं त्वामुस्रियाहव्यसूदः। अस्मे बलानि मघवत्सु धत्तं कृणुतं नो ऽ अध्वरं श्रुष्टिमंतं॥ २९। १२
अनुवाकः। १४ इमं स्तोममर्हते जातवेदसे रथमिव संमहेमा मनीषया। भद्रा हि नः प्रमतिरस्य
संसद्यग्ने सख्ये मा रिषामा वयं तव॥ यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यं। स तू
ताव नैनमश्नोत्यंहतिरग्ने०॥ शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदंत्याहुतं। त्वमादि
त्यांऽआ वह तान्ह्युश्मस्यग्ने०॥ भरामेध्मं कृणवामा हवींषि ते चितयंतः पर्वणापर्वणा वयं।
जीवातवे प्रतरं साधया धियो ऽग्ने स०॥ विशां गोपा ऽ अस्य चरंति जंतवो द्विपच्च यदुत चतुष्प
दक्तुभिः। चित्रः प्रकेत ऽ उषसो महाँऽअस्यग्ने०॥ ३० त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता
पोता जनुषा पुरोहितः। विश्वा विद्वाँऽआर्त्विज्या धीर पुष्यस्यग्ने स०॥ यो विश्वतः सुप्रतीकः स
दृङ्ङसि दूरे चित्सन्तळिदिवाति रोचसे। रात्र्याश्चिदंधो ऽ अति देव पश्यस्यग्ने०॥ पूर्वो देवा भ

सं·प्र·६ वतुसुन्वतोरथोऽस्माकंशंसोऽअभ्यस्तुदूढ्यः।तदाजानीतोतपुष्यतावचोऽग्ने॰॥वधैर्दुःशं
६३ साँऽअपदूढ्योजहिदूरेवायेऽअंतिवाकेचिदत्रिणः।अथायज्ञायगृणतेसुगंकृध्यग्नेस॰॥
यदयुक्थाऽअरुषारोहितारथेवातजूतावृषभस्येवतेरवः।आदिन्वसिवनिनोधूमकेतुना
ऽग्ने॰॥ ३१ अधस्वनादुतबिभ्युःपतत्रिणोद्रप्सायत्तेयवसादोव्यस्थिरन्।सुगंतत्तेताव
केभ्योरथेभ्यो ऽग्ने॰॥अयंमित्रस्यवरुणस्यधायसेऽवयातांमरुतांहेळोऽअद्भुतः।मृळा
सुनोभूत्वेषांमनःपुनरग्ने॰॥देवोदेवानामसिमित्रोऽअद्भुतोवसुर्वसूनामसिचारुरध्वरे।
शर्मन्त्स्यामतवसप्रथस्तमेऽग्ने॰॥तत्तेभद्रंयत्समिद्धःस्वेदमेसोमाहुतोजरसेमृळयत्तमः।
दधासिरत्नंद्रविणंचदाशुषेऽग्ने॰॥यस्मैत्वंसुद्रविणोददाशोऽनागास्त्वमदितेसर्वताता। ६३
यंभद्रेणशवसाचोदयासिप्रजावताराधसातेस्याम॥सत्वमग्नेसौभगत्वस्यविद्वानस्मा

कुमायुः प्रतिरिहदेवातन्नो मित्रो वरुणो मामहंताम‍दितिः सिंधुः पृथिवीऽउत द्यौः॥ ३२ ।
१६॥ १४॥ १६३ अर्धा। स्वना त्। उत। बिभ्युः। पतत्रिणः। द्रप्साः। यत्। ते। यवसऽअदः। वि।
अस्थिरन्। सुऽगा। नत्। ते। ताव्केभ्यः। रथेभ्यः॥ अर्यः। मित्रस्य। वरुणस्य। धायसे। अवऽयातां।
मरुतां। हेळः। अद्भुतः। मृळ। सु। नः। भूतु। एषां। मनः। पुनः॥ देवः। देवानां। असि। मित्रः। अद्भु
तः। वसुः। वसूनां। असि। चारुः। अध्वरे। शर्मन्। स्याम। तव। सुप्रथःऽतमे॥ नत्। ते। भद्रं। यत्। संऽ
इद्धः। स्वे। दमे। सोमऽआहुतः। जरसे। मृळयत्ऽतमः। दधासि। रत्नं। द्रविणं। च। दाशुषे॥ य
स्मै। त्वं। सुऽद्रविणः। ददाशः। अनागाःऽत्वं। अदिते। सर्वऽताता। यं। भद्रेण। शवसा। चोदयासि।
सि। प्रजाऽवता। राधसा। ते। स्याम। सः। त्वं। अग्ने। सौभगऽत्वस्य। विद्वान्। अस्माकं। आयुः। प्र।
तिर। इह। देव। तत्। नः। मित्रः। वरुणः। ममहंतां। अदितिः। सिंधुः। पृथिवी। उत। द्यौः॥ ३२ ॥

सं॰प्र॰७ इतिसंहिताप्रथमाष्टकेषष्ठोध्यायः॥ ॐ ह्वेएकादशोषुसायवाग्नयेसप्ततथानवद्र
६४ विणोदसेऽपनोष्टौशुचयेगायत्रंवैश्वानरस्यतृचंवैश्वानरीयंजातवेदसएकाजातवेदस्यमि
तदादीन्येकभूयांसिसूक्तसहस्रमेतत्कश्यपार्षंसयोवृषेकोनावार्षागिराऋज्राश्वांबरीष
सहदेवभयमानसुराधसःप्रमंदिनएकादशाकुत्सश्चतुस्त्रिष्टुबंतमाद्यागर्भस्राविण्युपनि
षदिमांतेंस्यात्रिष्टुबंतेष्टौयोनिर्णवचंद्रमाएकोनास्यत्रितोवावैश्वदेवंहिपांक्तमंत्यात्रिष्टुब
हृमीमहाबृहतीयवमध्येंद्रंमित्रंसप्तत्रिष्टुबंतंयइंद्रस्तृचंयदिंद्राग्नीसप्तैंद्राग्नंतुविह्यख्यंहोत
तंनवाभेवंतुपंचमंत्यत्रिष्टुभौतक्षन्पंचांत्यात्रिष्टुब्वीळुपंचाधिकाश्विनमाद्यौपादौलिंगोक्त
देवतावंत्येत्रिष्टुभौ॥ ७ ॐ ह्वेविरूपेचरतःस्वर्थेऽअन्यान्यावत्समुपधापयेतेह ६४
रिरन्यस्यांभवतिस्वधावान्छुक्रोऽअन्यस्यांददृशेसुवर्चाः॥दशेमंत्वष्टुर्जनयंतगर्भमतं

द्रासो युवतयो विभृत्रं। तिग्मानीकं स्वयशसं जनेषु विरोचमानं परिषीनयंति॥ त्रीणि जाना परिभूषंत्यस्य समुद्रऽएकं दिव्येकमप्सु। पूर्वामनु प्रदिशं पार्थिवानामृतून्प्रशासद्विदधावनुष्ठ॥ कऽइमं वो निण्यमाचिकेत वत्सो मातॄर्जनयत स्वधाभिः। बह्वीनां गर्भोऽअपसामुपस्थान्महान्कविर्निश्चरति स्वधावान्॥ आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशाऽउपस्थे। उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीचीसिंहं प्रतिजोषयेते॥ उभे भद्रे जोषयेते न मेने गावो न वाश्राऽउपतस्थुरेवैः। सदक्षाणां दक्षपतिर्बभूवांजंति यं दक्षिणतो हविर्भिः॥ उद्यंयमीति सवितेव बाहूऽउभे सिचौ यतते भीमऽऋंजन्। उच्छुक्रमत्कमजते सिमस्मान्नवा मातृभ्यो वसना जहाति॥ त्वेषरूपं कृणुतऽउत्तरं यत्संपृंचानः सदने गोभिरद्भिः। कविर्बुध्नं परिमर्मृज्यते धीः सा देवताता समितिर्बभूव॥ उरु ते ज्रयः पर्येति बुध्नं विरोचमानं महिषस्य धाम। विश्वेभिरग्ने

सं·अ·७ स्वयशोभिरिड्यो दैव्येभिः पायुभिः पाह्यस्मान्॥ धन्वन्त्स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभि·
६५ ने क्षतिक्ष्मां। विश्वासनोनिजठरेषु धत्तेंतर्नवासु चरति प्रसूषु॥ एवानोऽअग्ने समिधावृधानो रे
६।३२ वत्पावक श्रवसे विभाहि। तन्नो०॥ २।११ स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळ
धत्त विश्वा। आपश्च मित्रं धिषणा च साधन्देवाऽअग्निं धारयन्द्रविणोदां॥ स पूर्वया निविदा कव्य
तायोरिमाः प्रजाऽअजनयन्मनूनां। विवस्वता चक्षसा द्यामपश्च देवाऽअग्निं धारयन्०॥ तमीळ
त प्रथमं यज्ञसाधं विशऽआरीराहुतमृंजसानं। ऊर्जः पुत्रं भरतं सृप्रदानुं देवा०॥ स मातरि
श्वा पुरुवारपुष्टिर्विदद्गातुं तनयाय स्वर्वित्। विशां गोपा जनिता रोदस्योर्देवा०॥ नक्तोषासा
वर्णमामेम्याने धापयेते शिशुमेकं समीची। द्यावाक्षामा रुक्मोऽअंतर्विभाति देवा०॥ ३ ६५
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः। अमृतत्वं रक्षमाणासऽएनं देवा०॥

नूचँपुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षां। सतश्च गोपां भवतश्च भूरेर्देवा०॥ द्रवि
णोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्रयंसत्। द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासत
२ ते दीर्घमायुः॥ एवा नो अग्ने० तन्नो मित्रो०॥ ४ । १ अप नः शोशुचदघमग्ने शुशुग्ध्या रयिं।
अप नः शोशुचदघं॥ सुक्षेत्रिया सुगातुया वसूया च यजामहे। अप०॥ प्र यद्भन्दिष्ठ एषां प्रास्मा
कासश्च सूरयः। अप०॥ प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयं। अप०॥ प्र यदग्नेः सहस्वतो
विश्वतो यन्ति भानवः। अप०॥ त्वं हि विश्वतोमुख विश्वतः परिभूरसि। अप०॥ द्विषो नो विश्वतो
मुखाति नावेव पारय। अप०॥ स नः सिन्धुमिव नावयाति पर्षा स्वस्तये। अप०॥ ५ । ८ वैश्वा
नरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः। इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते
सूर्येण॥ पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश। वैश्वानरः सहसा पृ

सं·अ·७ ष्टो ऽ अग्निः सनो दिवा सरिषः पातु नक्तं ॥ वैश्वानर तव तत्सत्यमस्त्वस्मान्रायो मघवानः सचंतां ।
६६ तन्नो० ॥ ६ ॥ जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि वि
श्वा नावेव सिंधुं दुरितात्यग्निः ॥ ७ ॥ १ स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश्च स
म्राट् । सतीनसत्वा हव्यो भरेषु मरुत्वान्नो भवत्विंद्र ऊती ॥ यस्यानाप्तः सूर्यस्येव यामो भरेभरे
वृत्रहा शुष्मो ऽ अस्ति । वृषन्तमः सखिभिः स्वेभिरेवैर्मरुत्वां० ॥ दिवो न यस्य रेतसो दुघानाः पंथा
सो यंति शवसापरीताः । तरद्द्वेषाः सासहिः पौंस्येभिर्मरुत्वां० ॥ सो ऽ अंगिरोभिरंगिरस्तमो भूद्वृषा
वृषभिः सखिभिः सखा सन् । ऋग्मिभिर्ऋग्मी गातुभिर्ज्येष्ठो मरुत्वां० ॥ स सूनुभिर्न रुद्रेभिर्ऋभ्वा
नृषाह्ये सासह्वाँ ऽ अमित्रान् । सनीळेभिः श्रवस्यानि तूर्वन्मरुत्वां० ॥ ८ ॥ स मन्युमीः समदन ६६
स्य कर्ता ऽस्माकेभिर्नृभिः सूर्यं सनत् । अस्मिन्नहन्सत्पतिः पुरुहूतो मरुत्वां० ॥ तमूतयो रण

यन्छूरसातौ'तंक्षेमस्यक्षितयःकृण्वतत्रां।सविश्वस्यकरुणस्येशऽएको'मरुत्वां०॥तमप्सं
तशवसऽउत्सवेषु'नरोनरमवसेतंधनाय।सोऽअंधेचित्तमसिज्योतिर्विदन्'मरुत्वां०॥स
सव्येनयमतिव्राधतश्चि'त्सदक्षिणेसंगृभीताकृतानि।सकीरिणाचित्सनिताधनानि'मरु
त्वां०॥सग्रामेभिःसनितासरथेभि'र्विदेविश्वाभिःकृष्टिभिर्न्वद्य।सपौंस्येभिरभिभूरशस्ती'र्मरु
त्वां०॥ १ सजामिभिर्यत्समजातिमीह्ले'ऽजामिभिर्वापुरुहूतऽएवैः।अपांतोकस्यतनयस्य
जेषे'मरुत्वां०॥सवज्रभृद्दस्युहाभीमऽउग्रः'सहस्रचेताःशतनीथऽऋभ्वा।चम्रीषोनशवसापां
चजन्यो'मरुत्वान्नो०॥तस्यवज्रःक्रंदतिस्मत्स्वर्षा'दिवोनत्वेषोरवथःशिमीवान्।तंसचंतेस
नयस्तंधनानि'मरुत्वान्नो०॥यस्याजस्रंशवसामानमुक्थं'परिभुजद्रोदसीविश्वतःसीं।स
पारिषत्क्रतुभिर्मंदसानो'मरु०॥नयस्यदेवादेवतानमर्ताऽ'आपश्चनशवसोऽअंतमापुः।स

सं॰प्र॰७ प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च' मरु०॥ १० रोहिच्छ्यावा सुमदंशुर्ललामी' र्द्युक्षा राय ऽ ऋज्राश्व
६७ स्य। वृषण्वंतं बिभ्रती धूर्षु रथं' मंद्रा चिकेत नाहुषीषु विक्षु॥ एतत्यत्त ऽ इंद्र वृष्ण ऽ उक्थं' वार्षागि
रा ऽ अभिगृणंति राधः। ऋज्राश्वः प्रष्टिभिरंबरीषः' सहदेवो भयमानः सुराधाः॥ दस्यूञ्छिम्यूंश्च
पुरुहूत ऽ एवै' र्हत्वा पृथिव्यां शर्वा निबर्हीत्। सनत्क्षेत्रं सखिभिः श्वित्न्येभिः' सनत्सूर्यं सनदपः
सुवज्रः॥ विश्वाहेंद्रो ऽ अधिवक्ता नो ऽ अ' स्त्वपरिह्वृताः सनुयाम वाजं। तन्नो०॥ ११ । १९ प्रमं ६।३२
दिने पितुमदर्चता वचो' यः कृष्णगर्भा निरहन्नृजिश्वना। अवस्यवो वृषणं वज्रदक्षिणं' मरु
त्वंतं सख्याय हवामहे॥ यो व्यंसं जाहृषाणेन मन्युना' यः शंबरं यो ऽ अहन्पिप्रुमव्रतं। इंद्रो यः शु
ष्णमशुषं न्यावृण' ङ्मरुत्वंतं०॥ यस्य द्यावापृथिवी पौंस्यं मह' द्यस्य व्रते वरुणो यस्य सूर्यः। य ६७
स्येंद्रस्य सिंधवः सश्चति व्रतं' मरुत्वंतं०॥ यो ऽ अश्वानां यो गवां गोपति र्वशी' य ऽ आरितः क

मेणिकर्मणिस्थिरः। वीळोश्चिदिंद्रोयोऽअसुन्वतोवधो'मरुत्वंतं०॥ योविश्वस्यजगतःप्राणत
स्पति'र्योब्रह्मणेप्रथमोगाऽअविंदत्। इंद्रोयोदस्यूँरधराँऽअवातिर'न्मरुत्वंतं०॥ यःशूरेभिर्ह
व्योयश्चभीरुभि'र्योधावद्भिर्हूयतेयश्चजिग्युभिः। इंद्रंयंविश्वाभुवनाभिसंदधु'र्मरुत्वंतं०॥ १२
रुद्राणामेतिप्रदिशाविचक्षणो'रुद्रेभिर्योषातनुतेपृथुज्रयः। इंद्रंमनीषाऽअभ्यर्चतिश्रुतं'मरु
त्वंतं०॥ यद्वामरुत्वःपरमेसधस्थे'यद्वावमेवृजनेमादयासे। अतऽआयाह्यध्वरंनोऽअच्छा
त्वायाहविश्वेहूमासत्यराधः॥ त्वायेंद्रसोमंसुषुमासुदक्ष'त्वायाहविश्वेहूमाब्रह्मवाहः। अधा
नियुत्वःसगणोमरुद्भि'रस्मिन्यज्ञेबर्हिषिमादयस्व॥ मादयस्वहरिभि'र्येतऽइंद्र'विष्यस्वशि
प्रेविसृजस्वधेने। आत्वासुशिप्रहरयोवहंतु'शन्हव्यानिप्रतिनोजुषस्व॥ मरुत्स्तोत्रस्यवृज
नस्यगोपा'वयमिंद्रेणसनुयामवाजं। तन्नोमित्रोवरुणो०॥ १३ । ११ इमांतेधियंप्रभरेमहो

सं॰प्र॰७ महीमस्य स्तोत्रे धिषणा यत्तऽआनजे। तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्न
६८ नु॥ अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः। अस्मे सूर्याचन्द्रमसाभिच
क्षे श्रद्धे कमिन्द्र चरतो वितर्तुरं॥ तं स्मा रथं मघवन्प्राव सातये जैत्रं यं तेऽअनुमदाम संगमे। आ
जा नऽइन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ्छर्म यच्छ नः॥ वयं जयेम त्वया युजा वृतमस्माकमं
शमुदवा भरेभरे। अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणां मघवन्वृष्ण्या रुज॥ नाना हि त्वा ह
वमाना जनाऽइमे धनानां धर्तरवसा विपन्यवः। अस्माकं स्मा रथमा तिष्ठ सातये जैत्रं हीन्द्र नि
भृतं मनस्तव॥ २५ गोजिता बाहूऽअमितक्रतुः सिमः कर्मन्कर्मञ्छतमूतिः खजंकरः। अक
ल्पऽइन्द्रः प्रतिमानमोजसाथा जना वि ह्वयन्ते सिषासवः॥ उत्ते शतान्मघवन्नुच्च भूयसऽ ६८
उत्सहस्राद्रिरिचे कृष्टिषु श्रवः। अमात्रं त्वा धिषणा तित्विषे मह्यधा वृत्राणि जिघ्नसे पुरंदर॥

त्रिविष्टिधातु प्रतिमानमोजसस्तिस्रो भूमीर्नृपते त्रीणि रोचना। अतीदं विश्वं भुवनं ववक्षिथाशत्रु
रिंद्र जनुषा सनादसि॥ त्वां देवेषु प्रथमं हवामहे त्वं बभूथ पृतनासु सासहिः। सेमं नः कारुमुपमन्युमु
द्भिदमिंद्रः कृणोतु प्रसवे रथं पुरः॥ त्वं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन्महत्सु च। त्वामुग्र
मवसे सं शिशीमस्यथा न इंद्र हवनेषु चोदय॥ विश्वाहेंद्रो॰ तन्नो मित्रो॰॥ १५। ११ तत्तऽइंद्रि ११
यं परमं पराचैरधारयंत कवयः पुरेदं। क्षमेदमन्यद्दिव्यन्यदस्य समी पृच्यते समनेव केतुः॥ स धा
रयत्पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज। अहन्नहिमभिनद्रौहिणं व्यहन्व्यंसं मघवा शा
चीभिः॥ स जातूभर्मा श्रद्दधानऽओजः पुरो विभिंदन्नचरद्वि दासीः। विद्वान्वज्रिन्दस्यवे हेतिम
स्यार्यं सहो वर्धया द्युम्नमिंद्र॥ तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत्। उपप्रय
न्दस्युहत्याय वज्री यद्ध सूनुः श्रवसे नाम दधे॥ तदस्येदं पश्यता भूरि पुष्टं श्रदिंद्रस्य धत्तन वी

सं॰प्र॰७ यीय। सगा ऽ अविंदत्सो ऽ अविंदद्दश्वा'न्त्स ऽ ओषधीः सो ऽ अपः स वनानि॥ २६ भूरिकर्मणे वृषभा
६९ य वृष्णे' सत्यशुष्माय सुनवाम सोमं। य ऽ आदृत्या परिपंथीव शूरो' यज्वनो विभजन्नेति वेदः॥ तदिं
द्र प्रेव वीर्यं चकर्थ' यत्ससंतं वज्रेणाबोधयो हिं। अनु त्वा पत्नीर्हृषितं वयश्च' विश्वे देवासो ऽ अम
दन्ननु त्वा॥ शुष्णं पिप्रुं कुयवं वृत्रमिंद्र' यदावधीर्वि पुरः शंबरस्य। तन्नो०॥ २७।८ यो नि ष ऽ इं ८।३२
द्र निषदे ऽ अकारि' तमा निषीद स्वानो नार्वा। विमुच्या वयोवसायाश्वा'न्दोषा वस्तोर्वहीयसः प्र
पित्वे॥ ओ त्ये नर ऽ इंद्रमूतये गु'र्नू चित्तान्त्सद्यो ऽ अध्वनो जगम्यात्। देवासो मन्युं दासस्य श्चम्न'
न्ते न ऽ आ वक्षन्त्सुविताय वर्णं॥ अव त्मना भरते केतवेदा' ऽ अव त्मना भरते फेनमुदन्। क्षीरेण
स्नातः कुयवस्य योषे' हते ते स्यातां प्रवणे शिफायाः॥ युयोप नाभिरुपरस्यायोः' प्र पूर्वीभिस्ति ६९
रते राष्टि शूरः। अंजसी कुलिशी वीरपत्नी' पयो हिन्वाना ऽ उदभिर्भरंते॥ प्रति यत्स्या नीथादर्शि

दस्यो'रोकोनाच्छासदंनंजानतीगात्।अधस्मानोमघवञ्चर्कृतादिन्मानोमघेवनिःषपीपरादाः
॥ १८ सत्वंनऽइंद्रसूर्येसोऽअप्स्वनागास्त्वऽआभजजीवशंसे।मांतरांभुजमारीरिषोनः श्रद्धि
तंतेमहतऽइंद्रियाय॥अधामन्येश्रत्तेऽअस्माऽअधायि'वृषाचोदस्वमहतेधनाय।मानोऽअ
कृतेपुरुहूतयोना'विंद्रक्षुध्यद्भ्योवयऽआसुतिंदाः॥मानोवधीरिंद्रमापरादा'मानःप्रियाभोजना
निप्रमोषीः।आंडामानोमघवञ्छक्रनिर्भे'न्मानःपात्राभेत्सहजानुषाणि॥अर्वाङेहिसोमकामं
त्वाहु'रयंसुतस्तस्यपिबामदाय।उरुव्यचाजठरऽआवृषस्व'पितेवनःशृणुहिहूयमानः॥ १९।
१ चंद्रमाऽअप्स्वंतरासुपर्णोधावतेदिवि।नवोहिरण्यनेमयः'पदंविंदंतिविद्युतो'वित्तंमेऽ
अस्यरोदसी॥अर्थमिद्वाऽउऽअर्थिनऽ'आजायायुवतेपतिं।तुंजातेवृष्ण्यंपयः'परिदायरसं
दुहे'वित्तंमे०॥मोषुदेवाऽअदःस्व१रवपादिदिवस्परि।मासोम्यस्यशंभुवः'शूनेभूमकदाचन'

सं·प्र·७ वित्तं मे॰॥ यज्ञं पृच्छाम्यवमं स तद्दूतो वि वोचति। क्वऽऋतं पूर्व्यं गतं कस्तद्बिभर्ति नूतनो वित्तं मे॰॥
७० अमी ये देवाः स्थन त्रिष्वा रोचने दिवः। कद्वऽऋतं कदनृतं क्व प्रत्ना वऽआहुतिर्वित्तं मे॰॥ २०
कद्वऽऋतस्य धर्णसि कद्वरुणस्य चक्षणं। कदर्यम्णो महस्पथा ऽति क्रामेम दूढ्यो वित्तं मे॰॥
अहं सोऽअस्मि यः पुरा सुते वदामि कानि चित्। तं मा व्यन्त्याध्यो३ वृको न तृष्णजं मृगं वित्तं मे॰॥
सं मा तपन्त्यभितः सपत्नीरिव पर्शवः। मूषो न शिश्ना व्यदन्ति माध्यः स्तोतारं ते शतक्रतो वित्तं मे
॰॥ अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता। त्रितस्तद्वेदाप्त्यः स जामित्वाय रेभति वित्तं मे॰॥
अमी ये पंचोक्षणो मध्ये तस्थुर्महो दिवः। देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर्वित्तं मे॰॥
२१ सुपर्णाऽएतऽआसते मध्यऽआरोधने दिवः। ते सेधंति पथो वृकं तरंतं यह्वतीरपो वि ७०
त्तं मे॰॥ नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनं। ऋतमर्षंति सिंधवः सत्यं तातान सूर्यो वित्तं मे॰॥

अग्नेतवत्यदुक्थ्यं'देवेषस्त्याप्यं।सनःसत्तोमनुषदादेवान्यक्षिविदुष्टरो'वित्तंमेऽ॥सत्तोहो
तामनुषदा'देवाꣳअच्छाविदुष्टरः।अग्निर्हव्यासुषूदति'देवोदेवेषुमेधिरो'वित्तंमे०॥ब्रह्मो
ह्रुणोतिवरुणो'गातुविदंतमीमहे।व्यूर्णोतिहृदामतिं'नव्योजायतामृतं'वित्तंमे०॥ २२ अ
सौयःपंथाऽआदित्यो'दिविप्रवाच्यंकृतः।नसदेवाऽअतिक्रमे'तंमर्तासोनपश्यथ'वित्तंमे०॥
त्रितःकूपेवहितो'देवान्हवतऽऊतये।तच्छुश्रावबृहस्पतिः'कृण्वन्नंहूरणादुरु'वित्तंमे०॥अरु
णोमासकृद्वृकः'पथायंतंददर्शहि।उज्जिहीतेनिचाय्या'तष्टेवपृष्ट्यामयी'वित्तंमे०॥एनांगूषे
६।३२ णवयमिंद्रवंतो'भिष्यामवृजनेसर्ववीराः।तन्नो०॥ २३ ॥१९ अनुवाकः।१५ इंद्रंमित्रंवरु
णमग्निमूतये'मारुतंशर्धोऽअदितिंहवामहे।रथंनदुर्गाद्वसवःसुदानवो'विश्वस्मान्नोऽअंह
सोनिष्पिपर्तन॥तऽआदित्याऽआगतासर्वतातये'भूतदेवावृत्रतूर्येषुशंभुवः।रथंन०॥अवे

सं·प्र·७ तुनः पितरः सुप्रवाचना ऽउत देवी देवपुत्रे ऽऋतावृधा । रथं न ॥ नराशंसं वाजिनं वाजयन्नि
७१ ह क्षयद्वीरं पूषणं सुम्नैरीमहे । रथं न ॥ बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हितं
तदीमहे । रथं न ॥ इंद्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाह्ळ ऽऋषिरह्वदूतये । रथं न ॥
देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् । तन्नो ॥ २४ । ७ यज्ञो देवानां ६।२
प्रत्येति सुम्नमादित्यासो भवता मृळयंतः । आ वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवि
त्तरासत् ॥ उप नो देवा ऽअवसा गमंत्वंगिरसां सामभिः स्तूयमानाः । इंद्र ऽइंद्रियैर्मरुतो म
रुद्भिरादित्यैर्नो ऽअदितिः शर्म यंसत् ॥ तन्न ऽइंद्रस्तद्वरुणस्तदग्निस्तदर्यमा तत्सविता
६।३२ चनो धात् । तन्नो ॥ २५ । ३ य ऽइंद्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि ७१
चष्टे । तेना यातं सरथं तस्थिवांसा ऽथा सोमस्य पिबतं सुतस्य ॥ यावदिदं भुवनं विश्वम

स्त्युरुव्यचा वरिमता गभीरं। तावाँ ऽअयंपातवे सोमो ऽअस्त्वरमिंद्राग्नी मनसे युवभ्यां॥ चक्रा
थे हि सध्र्य१ङ्नाम भद्रं सध्रीचीना वृत्रहणा ऽउत स्थः। ताविंद्राग्नी सध्र्यंचा निषद्या वृष्णः सो
मस्य वृषणा वृषेथां॥ समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा। तीव्रैः सोमैः परि
षिक्तेभिरर्वागेंद्राग्नी सौमनसाय यातं॥ यानींद्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वृष्ण्या
नि। या वां प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य॥ २६ यदब्रवं प्रथमं वां वृ
णानो ऽयं सोमो ऽअसुरैर्नो विहव्यः। तां सत्यां श्रद्धामभ्या हि यातमथा सोमस्य पिबतं सु २५
तस्य॥ यदिंद्राग्नी मदथः स्वे दुरोणे यद्ब्रह्मणि राजनि वा यजत्रा। अतः परि वृषणावा हि या
तमथा सोमस्य पिबतं सुतस्य॥ यदिंद्राग्नी यदुषु तुर्वशेषु यद्द्रुह्युष्वनुषु पूरुषु स्थः। अ
तः परि०॥ यदिंद्राग्नी ऽअवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः। अतः परि०॥ य

सं·प्र·७ दिंद्राग्नी परमस्यां पृथिव्यां मध्यमस्यामवमस्यामुत स्थः। अतः परि०। यदिंद्राग्नी दिवि ष्ठो य
७२ त्पृथिव्यां यत्पर्वतेष्वोषधीष्वप्सु। अतः परि०। यदिंद्राग्नी ऽउदिता सूर्यस्य मध्ये दिवः स्वधया
मादयेथे। अतः परि०। एवेंद्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि। तन्नो०॥
२७। विह्यख्यं मनसा वस्य ऽइच्छन्निंद्राग्नी ज्ञास ऽउत वा सजातान्। नान्या युवत्प्रमति
रस्ति मह्यं स वां धियं वाजयंतीमतक्षं॥ अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा स्याला
त्। अथा सोमस्य प्रयती युवभ्यामिंद्राग्नी स्तोमं जनयामि नव्यं॥ मा च्छेद्म रश्मीँरिति नाधमा
नाः पितृणां शक्तीरनुयच्छमानाः। इंद्राग्निभ्यां कं वृषणो मदंति ता ह्यद्री धिषणाया ऽउपस्थे
॥ युवाभ्यां देवी धिषणा मदायेंद्राग्नी सोममुशती सुनोति। तावश्विना भद्रहस्ता सुपाणी ऽ ७२
आ धावतं मधुना पृङ्क्तमप्सु॥ युवामिंद्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये। तावास

द्यावा बर्हिषि यज्ञे ऽअस्मिन्प्रचर्षणी मादयेथां सुतस्य ॥ २८ प्रचर्षणिभ्यः पृतनाहवेषु प्र पृथि
व्या रिरिचाथे दिवश्च । प्र सिंधुभ्यः प्र गिरिभ्यो महित्वा प्रेंद्राग्नी विश्वा भुवनात्यन्या ॥ आ भरतं शि
क्षतं वज्रबाहू ऽअस्माँ इंद्राग्नी ऽअवतं शचीभिः । इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो
न ऽआसन् ॥ पुरंदरा शिक्षतं वज्रहस्ता ऽस्माँ इंद्राग्नी ऽअवतं भरेषु । तन्नो० ॥ २९ । ततं
मे ऽअपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते । अयं समुद्र ऽइह विश्वदेव्यः स्वाहा
कृतस्य समु तृप्णुत ऽऋभवः ॥ आभोगयं प्र यदिच्छंत ऽऐतनापाकाः प्रांचो मम के चिदापयः ।
सौधन्वनासश्चरितस्य भूमनागच्छत सवितुर्दाशुषो गृहं ॥ तत्सविता वोमृतत्वमासुवदगो
ह्यं यच्छ्रवयंत ऽऐतन । त्यं चिच्चमसमसुरस्य भक्षणमेकं संतमकृणुता चतुर्वयं ॥ विष्ट्वी शमी
तरणित्वेन वाघतो मर्तासः संतो ऽअमृतत्वमानशुः । सौधन्वना ऽऋभवः सूरचक्षसः संवत्स

 रेसमेष्टच्यंतधीतिभिः॥क्षेत्रमिवविमेमुस्तेजनेनऽ'एकंपात्रमृभवोजेहमानं।उपस्तुताऽउ
 पमंनाधमानाऽअमर्त्येषुश्रवऽइच्छमानाः॥ ३० ॥ आमनीषामंतरिक्षस्यनृभ्यः'स्रुचेव
घृतंजुहवामविद्मना।तरणित्वायेपितुरस्यसश्चिरऽ'ऋभवोवाजमरुहन्दिवोरजः॥ऋ
भुर्नऽइंद्रःशवसानवीयान्नृभुर्वाजेभिर्वसुभिर्वसुर्ददिः।युष्माकंदेवाऽअवसाहनिप्रियेऽ
'भितिष्ठेमपृत्सुतीरसुन्वतां॥निश्चर्मणऽऋभवोगामपिंशत'संवत्सेनासृजतामातरंपु
नः।सौधन्वनासःस्वपस्ययानरो'जिव्रीयुवानापितराकृणोतन॥वाजेभिर्नोवाजसाताववि
ढ्यृभुमाँऽइंद्रचित्रमादर्षिराधः।तन्नोमित्रो०॥ ३१ ॥ १ तक्षन्रथंसुवृतंविद्मनापस' ६।१२
स्तक्षन्हरीऽइंद्रवाहावृषण्वसू।तक्षन्पितृभ्यामृभवोयुवद्वय'स्तक्षन्वत्सायमातरंसचाभु
वं॥आनोयज्ञायतक्षतऽऋभुमद्वयः'क्रत्वेदक्षायसुप्रजावतीमिषं।यथाक्षयामसर्ववीर

या विशा तन्नः शर्धाय धासथा स्विंद्रियं ॥ आ तक्षत सातिमस्मभ्यमृभवः सातिं रथाय सातिमर्व
ते नरः । सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिं ॥ ऋभुक्षणमिंद्रमा हुव ऊ
तय ऋभून्वाजान्मरुतः सोमपीतये । उभा मित्रावरुणा नूनमश्विना ते नो हिन्वंतु सातये धिये
जिषे ॥ ऋभुर्भराय सं शिशातु सातिं समर्यजिद्वाजो अस्माँ अविष्टु । तन्नो० ॥ ३२ । ५ ईळे
द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये । याभिर्भरे कारमंशाय जिन्वथस्ता
भिरू षु ऊतिभिरश्विना गतं ॥ युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मंतवे ।
याभिर्धियोऽवथः कर्मन्निष्टये ताभि० ॥ युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य
मज्मना । याभिर्धेनुमस्वं पिन्वथो नरा ताभि० ॥ याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु
तरणिर्विभूषति । याभिस्त्रिमंतुरभवद्विचक्षणस्ताभिरू षु० ॥ याभी रेभं निवृतं सितमद्भ्य

सं०प्र०७ उद्वंदनमैरयतंस्वर्दृशे। याभिःकण्वंप्रसिषासंतमावतं'ताभि०॥ २३ याभिरंतकंजसमान
७४ मारणे'भुज्युंयाभिरव्यथिभिर्जिजिन्वथुः। याभिःकर्कंधुंवय्यंचजिन्वथ'स्ताभि०॥ याभिः
शुचंतिंधनसांसुषंसदं'तप्तंघर्ममोम्यावंतमत्रये। याभिःपृश्निगुंपुरुकुत्समावतं'ताभि०॥
याभिःशचीभिर्वृषणापरावृजं'प्रांधंश्रोणंचक्षसऽएतवेकृथः। याभिर्वर्तिकांग्रसितामर्मुचं
तं'ताभि०॥ याभिःसिंधुंमधुमंतमसश्चतं'वसिष्ठंयाभिरजरावजिन्वतं। याभिःकुत्संश्रुतर्यं
नर्यमावतं'ताभि०॥ याभिर्विश्पलांधनसामथर्व्यं'सहस्रमीळ्हऽआजावजिन्वतं। याभिर्वशं
मश्व्यंप्रेणिमावतं'ताभि०॥ २४ याभिःसुदानूऽऔशिजायवणिजे'दीर्घश्रवसेमधुकोशोऽ
अक्षरत्। कक्षीवंतंस्तोतारंयाभिरावतं'ताभि०॥ याभीरसांक्षोदसोद्नःपिपिन्वथु'रनश्वंया ७४
भीरथमावतंजिषे। याभिस्त्रिशोकऽउस्त्रियाऽउदाजत'ताभि०॥ याभिःसूर्यंपरियाथःपराव

तिं मंधातारं क्षेत्रपत्येष्वावतं । याभिर्विप्रं प्रभरद्वाजमावतं ताभि० ॥ याभिर्महामतिथिग्वं कशो
जुवं दिवोदासं शंबरहत्यऽआवतं । याभिः पूर्भिद्ये त्रसदस्युमावतं ताभि० ॥ याभिर्वम्रं विपि
पानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः । याभिर्व्यश्वमुत पृथिमावतं ताभि० ॥ ३५ या
भिर्नरा शयवे याभिरत्रिं याभिः पुरा मनवे गातुमीषथुः । याभिः शारीराजतं स्यूमरश्मये ताभि० ॥
याभिः पठर्वा जठरस्य मज्मनाऽग्निर्नादीदेच्चितऽइद्धोऽअज्मन्ना । याभिः शर्यातमवथो महाध
ने ताभि० ॥ याभिरंगिरो मनसा निरण्यथोऽग्रं गच्छथो विवरे गोऽअर्णसः । याभिर्मनुं शूरमिषा
समावतं ताभि० ॥ याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षतं । याभिः सुदासऽऊह
थुः सुदेव्यं १ ताभि० ॥ याभिः शंताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुं । ओम्याव
तीं सुभरामृतस्तुभं ताभि० ॥ ३६ याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनोऽअर्वंतमावतं ।

सं·प्र·७ मधुप्रियंभरथोयत्सरड्भ्यस्ताभिरू॥याभिर्नरंगोषुयुधंनृषाह्येक्षेत्रस्यसातातनयस्यजिन्वथः।
७५ याभीरथाँ॥अवथोयाभिरर्वतस्ताभिरू॥याभिःकुत्समार्जुनेयंशतक्रतूप्रतुर्वीतिंप्रचदभीति
मावतं।याभिर्ध्वसंतिंपुरुषंतिमावतंताभिरू॥अप्नस्वतीमश्विनावाचमस्मेकृतंनोदस्रावृष
३।५ णामनीषां।अद्यूत्येवसेनिह्वयेवांवृधेचनोभवतंवाजसातौ॥द्युभिरक्तुभिःपरिपातमस्मान
६।३२ रिष्टेभिरश्विनासौभगेभिः।तन्नोरू॥ ३७ । २५॥१८॥१७९॥ याभिः।कृशानुं।असने।दुव
स्यः।जवे।याभिः।यूनः।अर्वंतं।आवतं।मधु।प्रियं।भरथः।यत्।सरट्ऽभ्यः।०।याभिः।नरं।गोषुऽ
युधं।नृऽसह्ये।क्षेत्रस्य।साता।तनयस्य।जिन्वथः।याभिः।रथान्।अवथः।याभिः।अर्वतः।०
याभिः।कुत्सं।आर्जुनेयं।शतक्रतू इति शतऽक्रतू।प्र।तुर्वीतिं।प्र।च।दभीतिं।आवतं।याभिः। ७५
ध्वसंतिं।पुरुऽसंतिं।आवतं।०।अप्नस्वतीं।अश्विना।वाचं।अस्मे इति।कृतं।नः।दस्रा।वृष

पा। मनीषां। अद्यूत्यै। अवसा। नि। ह्वये। वां। ०। द्युभिः। अक्तुऽभिः। परि। पातं। अस्मान्। अरि
ष्टेभिः। अश्विना। सौभगेभिः। ०॥ ३ ७॥ ॐ ३ इतिसंहिताप्रथमाष्टकेसप्तमोध्यायः॥
ॐ इदंविंशतिरुषस्यंद्वितीयोर्धर्चोरात्रेश्चेमाएकादशारोईद्वित्रिष्टुबंतंचित्रंषट्सोर्यैना
सत्याभ्यांपंचाधिकाकक्षीवान्दैर्घतमसउशिक्सूतआश्विनंवैमध्वआवामेकादशा
वारथंदशाजागतंकाराधद्वादशांत्यादुःस्वप्ननाशिन्योद्यागायत्रीद्वितीयाककुप्तृतीयाचतु
र्थ्यौकाविराण्नष्टरूप्यौपंचमीतनुशिरापष्ठ्यक्षरैरुष्णिग्विष्टारबृहतीकृतिर्विराडितिस्त्रोगा
यत्र्यःककुदिस्थापंचोनावैश्वदेवंवा॥ ८ ॐ इदंश्रेष्ठंज्योतिषांज्योतिरागा'च्चित्रःप्रकेतोऽअज
निष्टविभ्वा। यथाप्रसूतासवितुःसवायँ एवारात्र्युषसेयोनिमारैक्॥ रुशद्वत्सारुशतीश्वेत्या
गा'दारैगुकृष्णासदनान्यस्याः। समानबंधूऽअमृतेऽअनूची'द्यावावर्णंचरतऽआमिना

सं·प्र·८ ने॥समानोऽअध्वास्वस्रोरनंत'स्तमन्यान्याचरतोदेवशिष्टे।नमेथेतेनतस्थतुःसुमेके'न
७६ क्तोषासासमनसाविरूपे॥भास्वतीनेत्रीसूनृतानामचेतिचित्राविदुरोनऽआवः।प्रार्प्याज ६।३२
गद्व्युनोरायोऽअख्य'दुषाऽअजीगर्भुवनानिविश्वा॥जिह्मश्येचरितवेमघो'न्याभोगय
ऽइष्टयेरायऽउत्वं।दभ्रंपश्यद्भ्यऽउर्वियाविचक्षऽ'उषा०॥ १ ॥क्षत्रायत्वंश्रवसेत्वंमहीयाऽ'
इष्टयेत्वमर्थमिवत्वमित्यै।विसदृशाजीविताभिप्रचक्षऽ'उषा०॥एषादिवोदुहिताप्रत्यदर्शि'
व्युच्छंतीयुवतिःशुक्रवासाः।विश्वस्येशानापार्थिवस्यवस्वऽ'उषोऽअद्येहसुभगेव्युच्छ॥
परायतीनामन्वेतिपाथऽ'आयतीनांप्रथमाशश्वतीनां।व्युच्छंतीजीवमुदीरयं'त्युषामृतं
कंचनबोधयंती॥उषोयदग्निंसमिधेचकर्थ'वियदावश्चक्षसासूर्यस्य।यन्मानुषान्यक्ष्य ७६
माणाँऽअजीग'स्तद्देवेषुचकृषेभद्रमप्नः॥कियात्यायत्समयाभवाति'याव्यूषुर्याश्चनूनंव्यु

च्छान्।अनुपूर्वीःकृपतेवावशाना'प्रदीध्यानाजोषमन्याभिरेति॥ २ ईयुष्टेयेपूर्वतरामपश्य'
न्व्युच्छंतीमुषसंमर्त्यासः।अस्माभिरूनुप्रतिचक्ष्याभू'दोतेयंतियेऽअपरीषुपश्यान्॥याव
यद्द्वेषाऽऋतपाऽऋतेजाः'सुम्नावरीसूनृताऽईरयंती।सुमंगलीर्बिभ्रतीदेववीतिं'मिहाद्योषःश्रे
ष्ठतमाव्युच्छ॥शश्वत्पुरोषाव्युवासदे'व्यथोऽअद्येदंव्यावोमघोनी।अथोव्युच्छादुत्तराँऽअनुद्यू'
नजरामृताचरतिस्वधाभिः॥व्यं१जिभिर्दिवऽआतास्वद्यौ'दपकृष्णांनिर्णिजंदेव्यावः।प्रबोधयंत्य
रुणेभिरश्वै'रोषायातिसुयुजारथेन॥आवहंतीपोष्यावार्याणि'चित्रंकेतुंकृणुतेचेकिताना।ईयुषी'
णामुपमाशश्वतीनां'विभातीनांप्रथमोषाव्यश्वैत्॥ ३ उदीर्ध्वंजीवोऽअसुर्नऽआगा'दपप्रागा
त्तमऽआज्योतिरेति।आरैक्पंथांयातवेसूर्या'यागन्मयत्रप्रतिरंतऽआयुः॥स्यूमनावाचऽउदि
यर्तिवह्निः'स्तवानोरेभऽउषसोविभातीः।अद्यातदुच्छगृणतेमघो'न्यस्मेऽआयुर्निदिदीहिप्र

सं·प्र·८ जावत॥ यागोमतीरुषसःसर्ववीरा 'व्युच्छंतिदाशुषेमर्त्याय। वायोरिवसूनृतानामुदर्के'ताऽ
७७ अश्वदाऽअश्नवत्सोमसुत्वा॥ मातादेवानामदितेरनीकं'यज्ञस्यकेतुर्बृहतीविभाहि। प्रशस्ति
कृद्ब्रह्मणेनोव्यु१च्छा नोजनेजनयविश्ववारे॥ यच्चित्रमप्नऽउषसोवहंती'जानायशशमा
६।२२ नायभद्रं। तन्नो०॥ ४।२० इमारुद्रायतवसेकपर्दिने'क्षयद्वीरायप्रभरामहेमतीः। यथा
शमसद्द्विपदेचतुष्पदे'विश्वंपुष्टंग्रामेऽअस्मिन्ननातुरं॥ मृळानोरुद्रोतनोमयस्कृधि'क्षय
द्वीरायनमसाविधेमते। यच्छंचयोश्चमनुरायेजेपिता'तदश्यामतवरुद्रप्रणीतिषु॥ अश्या
मतेसुमतिंदेवयज्यया'क्षयद्वीरस्यतवरुद्रमीढ्वः। सुम्नायन्निद्विशोऽअस्माकमाचर'रिष्ट
वीराजुहवामतेहविः॥ त्वेषंवयंरुद्रंयज्ञसाधं'वंकुंकविमवसेनिह्वयामहे। आरेऽअस्मद्दै ७७
व्यंहेळोऽअस्यतु'सुमतिमिद्वयमस्यावृणीमहे॥ दिवोवराहमरुषंकपर्दिनं'त्वेषंरूपंनमः

मानिह्वयामहे। हस्तेबिभ्रद्भेषजावार्याणि'शर्मवर्मच्छर्दिरस्मभ्यंयंसत्॥ ५ इदंपित्रेमरुता
मुच्यतेवचः'स्वादोःस्वादीयोरुद्रायवर्धनं। रास्वाचनोऽअमृतमर्तभोजनं'त्मनेतोकायतन
यायमृळ॥ मानोमहांतमुतमानोऽअर्भकं'मानऽउक्षंतमुतमानऽउक्षितं। मानोवधीःपितरं
मोतमातरं'मानःप्रियास्तन्वोरुद्ररीरिषः॥ मानस्तोकेतनयेमानऽआयौ'मानोगोषुमानोऽ
अश्वेषुरीरिषः। वीरान्मानोरुद्रभामितोवधी'र्हविष्मंतःसदमित्त्वाहवामहे॥ उपतेस्तोमान्प
शुपाऽइवाकरं'रास्वापितर्मरुतांसुम्नमस्मे। भद्राहितेसुमतिर्मृळयत्तमा'थावयमवऽइत्ते
वृणीमहे॥ आरेतेगोघ्नमुतपूरुषघ्नं'क्षयद्वीरसुम्नमस्मेतेऽअस्तु। मृळाचनोऽअधिचब्रू
हिदेवाधाचनःशर्मयच्छद्विबर्हाः॥ अवोचामनमोऽअस्माऽअवस्यवः'शृणोतुनोहवंरु
६।२२ द्रोमरुत्वान्। तन्नो॥ ६। ११ चित्रंदेवानामुदगादनीकं'चक्षुर्मित्रस्यवरुणस्याग्नेः।

सं·प्र·८ आप्रा द्यावापृथिवी ऽअंतरिक्षं सूर्य ऽआत्मा जगतस्तस्थुषश्च॥ सूर्यो देवीमुषसं रोचमानां
७८ मर्यो न योषामभ्येति पश्चात्। यत्रा नरो देवयंतो युगानि वितन्वते प्रति भद्राय भद्रं॥ भद्रा ऽ
अश्वा हरितः सूर्यस्य चित्रा ऽएतग्वा ऽअनुमाद्यासः। नमस्यंतो दिव ऽआ पृष्ठमस्थुः परि
द्यावापृथिवी यंति सद्यः॥ तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं संजभार। यदेदयुक्त
हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै॥ तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणु
ते द्योरुपस्थे। अनंतमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः संभरंति॥ अद्या देवा ऽउदिता
सूर्यस्य निरंहसः पिपृता निरवद्यात्। तन्नो मित्रो०॥ ७। १६ अनुवाकः। १६ नासत्याभ्यां १।२
बर्हिरिव प्र वृंजे स्तोमाँ इयर्म्यभ्रियेव वातः। यो अर्भगाय विमदाय जायां सेनाजुवा न्यू ७८
हतू रथेन॥ वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना। तद्रासभो नासत्या

सहस्त्रमाजा यमस्य प्रधने जिगाय॥ तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवाँ अवाहाः
। तमूहथुर्नौभिरात्मन्वतीभिरंतरिक्षप्रुद्भिरपोदकाभिः॥ तिस्त्रः क्षपस्त्रिरहातिव्रजद्भिर्नास
त्या भुज्युमूहथुः पतंगैः॥ समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः॥ अना
रंभणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे। यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां
नावमातस्थिवांसं॥ ६ यमश्विना ददथुः श्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति। तद्वां दा
त्रं महि कीर्तेन्यं भूत्पैद्वो वाजी सदमिद्धव्यो अर्यः॥ युवं नरा स्तुवते पज्रियाय कक्षीवते
अरदतं पुरंधिं। कारोतराच्छफादश्वस्य वृष्णः शतं कुंभाँ असिंचतं सुरायाः॥ हिमेनाग्निं घ्रं
समवारयेथां पितुमतीमूर्जमस्मा अधत्तं। ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः स
र्वगणं स्वस्ति॥ परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारं। क्षरन्नापो न पायना

यरा॒ये स॒हस्रा॑य॒ तृष्य॑ते॒ गोत॑मस्य॥ जु॒जु॒रुषो॑ नासत्यो॒त व॒व्रिं प्रामुं॑चतं द्रा॒पिमि॑व॒ च्यवा॑नात्।
प्राति॑रतं जहि॒तस्यायु॑र्दस्रा॒ऽऽदित्पति॑मकृणुतं क॒नीना॑म्॥ ९ तद्वां॑ नरा॒ शंस्यं॒ राध्यं॑ चाभि॒
ष्टिम॑न्नासत्या॒ वरू॑थम्। यद्वि॒द्वांसा॑ नि॒धिमि॒वाप॑गूळ्ह॒मुद्द॑र्श॒तादू॒पथु॒र्वंद॑नाय॥ तद्वां॑ नरा स॒न
ये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिम्। द॒ध्यङ् ह॒ यन्मध्वा॑थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी॑
मु॒वाच॑॥ अजो॑हवीन्नासत्या क॒रा वां॑ म॒हे याम॑न्पुरुभुजा॒ पुरं॑धिः। श्रु॒तं तच्छा॒सुरि॑व वध्रिम॒त्या
हिर॑ण्यहस्तमश्विनावदत्तम्॥ आ॒स्नो वृक॑स्य व॒र्तिका॑म॒भीके॑ यु॒वं न॑रा नासत्यामुमुक्तम्। उ॒तो क॒
विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे॑॥ च॒रित्रं॒ हि वेरि॒वाच्छे॑दि प॒र्णमा॒जा खेल॑स्य॒ प
रि॑तक्म्यायाम्। स॒द्यो जंघा॒माय॑सीं वि॒श्पला॑यै॒ धने॑ हि॒ते सर्त॑वे॒ प्रत्य॑धत्तम्॥ १० श॒तं मे॒षान्वृ॒
क्ये॑ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तान्धं च॑कार। तस्मा॑ अ॒क्षी ना॑सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिष

जावनुर्वेन॥ आवांरथंदुहितासूर्यस्यकार्ष्मेवातिष्ठदर्वताजयंती। विश्वेदेवाऽअन्वमन्यंतहृ
द्भिःसमुश्रियानासत्यासचेथे॥ यदयातंदिवोदासायवर्तिर्भरद्वाजायाश्विनाहयंता। रेवदु
वाहसचनोरथोवांवृषभश्चशिंशुमारश्चयुक्ता॥ रयिंसुक्षत्रंस्वपत्यमायुःसुवीर्यंनासत्याव
हंता। आजह्नावींसमनसोपवाजैस्त्रिरह्नोभागंदधतीमयातं॥ परिविष्टंजाहुषंविश्वतःसीं
सुगेभिर्नक्तमूहथूरजोभिः। विभिंदुनानासत्यारथेनविपर्वताँऽअजरयूऽअयातं॥ ११ एक
स्यावस्तोरावतंरणायवशमश्विनासनयेसहस्रा। निरहतंदुच्छुनाऽइंद्रवंतापृथुश्रवसोवृ
षणावरातीः॥ शरस्यचिदार्चत्कस्यावतादानीचादुच्चाचक्रथुःपातवेवाः। शयवेचिन्नासत्या
शचीभिर्जसुरयेस्तर्यंपिप्यथुर्गां॥ अवस्यतेस्तुवतेकृष्णियायऽऋजूयतेनासत्याशचीभिः।
पशुंननष्टमिवदर्शनायविष्णाप्वंददथुर्विश्वकाय॥ दशरात्रीरशिवेनानवद्यूनवनद्धंश्नथि

सं·अ·८ तमप्स्वं१॒न्तः।विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि॑न्यथुः॒ सोम॑मिव स्रु॒वेण॑॥प्र वां॒ दंसां॑स्यश्विनाववो
८० चमस्य॒ पतिः॑ स्यां सु॒गवः॑ सु॒वीरः॑।उ॒त पश्य॑न्नश्नु॒वन्दी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं॑ जगम्यां॥
१२।२५ मध्वः॒ सोम॑स्याश्विना॒ मदा॑य प्र॒त्नो होता विवा॑सते वां।ब॒र्हिष्म॑ती रा॒तिर्विश्रि॑ता॒ गी
रि॒षा या॑तं नासत्योप॒ वाजैः॑॥यो वा॑मश्विना॒ मन॑सो॒ जवी॑या॒न्रथः॑ स्व॒श्वो विश॑ आ॒जिगा॑ति।
येन॒ गच्छ॑थः सु॒कृतो॑ दुरो॒णं तेन॑ नरा व॒र्तिर॒स्मभ्यं॑ यातं॥ऋषिं॑ नरा॒वंह॑सः॒ पाञ्च॑जन्यमृ॒बीसा॑
दत्रिं॑ मुञ्चथो ग॒णेन॑।मि॒नन्ता॒ दस्यो॒रशि॑वस्य मा॒या अ॑नुपू॒र्वं वृ॑षणा चो॒दय॑न्ता॥अश्वं॒ न गू॒ळ्हम
श्विना दु॒रेवै॒रृषिं॑ नरा वृषणा रे॒भम॒प्सु।सं तं रि॑णीथो॒ विप्रु॑तं॒ दंसो॑भि॒र्न वां॑ जूर्यन्ति पू॒र्व्या कृ॒तानि॑॥
सुषु॒प्वांसं॒ न निर्ऋ॑तेरु॒पस्थे॒ सूर्यं॒ न द॑स्रा॒ तम॑सि क्षि॒यन्तं॑।शु॒भे रु॒क्मं न द॑र्श॒तं निखा॑त॒मुदू॑प ८०
१० थुरश्विना॒ वन्द॑नाय॥ १३ यद्वां॑ नरा॒ शंस्यं॑ प॒ज्रियेण॑ क॒क्षीव॑ता नासत्या॒ परि॑ज्मन्।श॒फादश्व

स्य वाजिनो जना य॑ शतं कुंभाँ असिंचतं मधूनां ॥ युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्वि
श्वकाय । घोषायै चित्पितृषदे दुरोणे पतिं जूर्यंत्या अश्विना वदत्तं ॥ युवं श्यावाय रुशतीमद
त्तं मुहः क्षोणस्या श्विना कण्वाय । प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तं ॥
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वं । सहस्रसां वाजिनमप्रतीतमहिहनं श्रव
स्यं तरुत्रं ॥ एतानि वां श्रवस्या सुदानू ब्रह्मांगूषं सदनं रोदस्योः । यद्वां पज्रासो अश्विना हवं
ते यातमिषा च विदुषे च वाजं ॥ २५ सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदंता ।
अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतं ॥ कुह यांता सुष्टुतिं काव्यस्य दिवो नपा
ता वृषणा शयुत्रा । हिरण्यस्येव कलशं निखातमुदूहथुर्दशमे अश्विनाहन् ॥ युवं च्यवानम
श्विना जरंतं पुनर्युवानं चक्रथुः शचीभिः । युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥

सं.प्र.८ ता ॥ युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना । युवं भुज्युमर्णसो निःसमुद्राद्विभिरूहथु
८१ र्ऋज्रेभिरश्वैः ॥ अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् । निष्टमूहथुः सुयु
जा रथेन मनोजवसा वृषणा स्वस्ति ॥ १५ अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुंच
तं वृकस्य । वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचोऽअहतं विषेण ॥ शतं मेषान्वृक्ये मामहा
नं तमः प्रणीतमशिवेन पित्रा । आक्षीऽऋज्राश्वेऽअश्विनावधत्तं ज्योतिरंधाय चक्रथुर्वि
चक्षे ॥ शुनमंधाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति । जारः कनीनऽइव चक्षदानऽ
ऋज्राश्वः शतमेकं च मेषान् ॥ मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या संरिणीथः ।
अथा युवामिदह्वयत्पुरंधिरागच्छतं सीं वृषणाववोभिः ॥ अधेनुं दस्रा स्तर्यं विषक्ता ८१
मपिन्वतं शयवेऽअश्विना गां । युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषां ॥ १६

यवंवृकेणाश्विनावपंते'षंदुहंतामनुषायदस्रा।अभिदस्युंबकुरेणाधमंतोरुज्योतिश्चक्रथु
रार्याय॥आथर्वणायाश्विनादधीचे'ऽश्व्यंशिरःप्रत्यैरयतं।सवांमधुप्रवोचदृतायंत्वाष्ट्रंय
द्दस्रावपिकक्ष्यंवां॥सदाकवीसुमतिमाचकेवां'विश्वाधियोऽअश्विनाप्रावतंमे।अस्मेरयिंना
सत्याबृहंतमपत्यसाचंश्रुत्यंरराथां॥हिरण्यहस्तमश्विनारराणा'पुत्रंनरावध्रिमत्याऽअदत्तं।
त्रिधाहश्यावमश्विनाविकस्तं'मुज्जीवसेऽऐरयतंसुदानू॥एतानिवामश्विनावीर्याणि'प्रपूर्व्या
ण्यायवोवोचन्।ब्रह्मकृण्वंतोवृषणायुवभ्यां'सुवीरासोविदथमावदेम॥ १७। २५ आवां
रथोऽअश्विनाश्येनपत्वा'सुमृळीकःस्ववांयात्वर्वाङ्।योमर्त्यस्यमनसोजवीयान्'त्रिवंधुरोवृ
षणावातरंहाः॥त्रिवंधुरेणत्रिवृतारथेन'त्रिचक्रेणसुवृतायातमर्वाक्।पिन्वतंगाजिन्वतम
र्वतोनो'वर्धयतमश्विनावीरमस्मे॥प्रवद्यामनासुवृतारथेन'दस्राविमंशृणुतंश्लोकमद्रेः।

सं·प्र·८ किमंगवांप्रत्यवर्तिंगमिष्ठाऽऽहुर्विप्रासोऽअश्विनापुराजाः।।आवांश्येनासोऽअश्विनावहंतु
८२ रथेयुक्तासऽआशवःपतंगाः।येऽअप्तुरोदिव्यासोनगृध्राऽअभिप्रयोनासत्यावहंति।।आवां ११
रथेयुवतिस्तिष्ठदत्रंजुष्ट्वीनरादुहितासूर्यस्य।परिवामश्वावपुषःपतंगाःवयोवहंत्वरुषाऽअ
भीके।। १८ उद्वंदनमैरतंदंसनाभिरुद्रेभंदस्रावृषणाशचीभिः।निष्टौग्र्यंपारयथःसमुद्रात्पुन
श्च्यवानंचक्रथुर्युवानं।।युवमत्रयेवनीतायतप्तमूर्जमोमानमश्विनावधत्तं।युवंकण्वायापिरि
प्तायचक्षुःप्रत्यधत्तंसुष्टुतिंजुजुषाणा।।युवंधेनुंशयवेनाधितायापिन्वतमश्विनापूर्व्याय।अमुं
चतंवर्तिकामंहसोनिःप्रतिजंघांविश्पलायाऽअधत्तं।।युवंश्वेतंपेदवऽइंद्रजूतमहिहनमश्वि
नादत्तमश्वं।जोहूत्रमर्योऽअभिभूतिमुग्रंसहस्रसांवृषणंवीड्वंगं।।तावांनरास्ववसेसुजाताहवा ८२
महेऽअश्विनानाधमानाः।आनऽउपवसुमतारथेनगिरोजुषाणासुविताययातं।।आश्येनस्य

जवसा नूतनेना स्मे यातं नासत्या सजोषाः। हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्यु
११ ष्टौ॥ १९ । ११ आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे। सहस्रकेतुं वनिनं शतद्व
सुं श्रुष्टीवानं वरिवोधामभि प्रयः॥ ऊर्ध्वा धीतिः प्रत्यस्य प्रयामन्यधायि शस्मन्त्समयन्त आ
दिशः। स्वदामि घर्मं प्रति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत्॥ सं यन्मिथः पस्पृधानासो
अग्मत शुभे मखा अमिता जायवो रणे। युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा व
रं॥ युवं भुज्युं भुरमाणं विभिर्गतं स्वयुक्तिभिर्निवहन्ता पितृभ्य आ। यासिष्टं वर्तिर्वृषणा विजेन्यं
दिवोदासाय महि चेति वामवः॥ युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यं। आ वां प
तित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवां पती॥ २० युवं रेभं परिषूतेरुरुष्यथो हिमेन घ
र्मं परितप्तमत्रये। युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वन्दनस्तार्यायुषा॥ युवं वन्दनं निर्ऋतं ज

सं·प्र·८ रण्यया रथं न दस्रा करणा समिन्वथः। क्षेत्रादा विप्रं जनथो विपन्यया प्र वामत्र विधते दंसना भुव
८३ त्॥ अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितं। स्वर्वतीरित ऽ ऊतीर्युवोरह चित्रा ऽ
अभीके ऽ अभवन्नभिष्टयः॥ उत स्या वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति। युवं द
धीचो मन ऽ आ विवासथोऽथा शिरः प्रति वामश्व्यं वदत्॥ युवं पेदवे पुरुवारमश्विना स्पृधां श्वेतं त
६ रुतारं दुवस्यथः। शर्यैरभिद्युं पृतनासु दुष्टरं चर्कृत्यमिंद्रमिव चर्षणीसहं॥ २१ । १० काराधद्धो
त्राश्विना वां को वां जोष ऽ उभयोः। कथा विधात्यप्रचेताः॥ विद्वांसा विद्दुरः पृच्छेदविद्वानित्था
परो ऽ अचेताः। नू चिन्नु मर्ते ऽ अक्रौ॥ ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य। प्रा
× र्चद्दयमानो युवाकुः॥ वि पृच्छामि पाक्या३ न देवान्वषट्कृतस्याद्भुतस्य दस्रा। पातं च सह्य ८३
सो युवं च रभ्यसो नः॥ प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वां। प्रैषयुर्न

विद्वान्॥ २२ श्रुतंगायत्रंतकवानस्याहंचिद्धिरिरेभा'श्विनावां॥आक्षीशुभस्पतीदन्॥युवंह्या
स्तंमहोरन्'युवंवायन्निरततंसतं॥तानोवसूसुगोपास्यातं'पातंनोवृकादघायोः॥माकस्मैधा
तमभ्यमित्रिणेनो'माकुत्रानोगृहेभ्योधेनवोगुः॥स्तनाभुजोऽअशिश्वीः॥दुहीयन्मित्रधितये
युवाकु'रायेचनोमिमीतंवाजवत्यै॥इषेचनोमिमीतंधेनुमत्यै॥अश्विनोरसनंरथमनश्वंवाजि
नीवतोः॥तेनाहंभूरिचाकन॥अयंसमहमातनू'ह्यातेजनाँऽअनु॥सोमपेयंसुखोरथः॥अ
धस्वप्नस्यनिर्विदे'भुंजतश्चरेवतः॥उभातावस्त्रिनश्यतः॥ २३ । १२ अनुवाकः। १७
कदित्थानॄँ'पात्रंदेवयतां'श्रवद्गिरोऽअंगिरसांतुरण्यन्॥प्रयदानड्विशऽआहर्म्यस्यो'रुक्रं
सतेऽअध्वरेयजत्रः॥स्तंभीद्धद्यांसधरुणंप्रुषाय'दृभुर्वाजायद्रविणंनरोगोः॥अनुस्वजां
महिषश्चक्षतव्रां'मेनामश्वस्यपरिमातरंगोः॥नक्षद्धवमरुणीःपूर्व्यंराट्'तुरोविशामंगि

सं॰प्र॰८ रसामनुद्यूनातक्षद्वज्रंनियुतंतस्तंभद्यां'चतुष्पदेनर्यायद्विपादे॥अस्यमदेस्वर्यंदाऽऋतायां
८४ पीवृतमुस्रियाणामनीकं।यद्धप्रसर्गेत्रिककुन्निवर्त'दपद्रुहोमानुषस्यदुरोवः॥तुभ्येत्पयोय
त्पितरावनीतां'राधःसुरेतस्तुरणेभुरण्यू।शुचियत्तेरेक्णऽआयजंतसबर्दुघायाःपयऽउस्रि
यायाः॥ २४ अधप्रजज्ञेतरणिर्ममत्तुप्ररोच्यस्याऽउषसोनसूरः।इंदुर्येभिराष्टस्वेदुहव्यैः'स्रु
वेणसिंचन्जरणाभिधाम॥स्विध्मायद्वनधितिरपस्यात्'सूरोऽअध्वरेपरिरोधनागोः।यद्धप्र
भासिकृत्व्याँऽअनुद्यून'नर्विशेपश्विषेतुराय॥अष्टामहोदिवऽआदोहरीऽइह'द्युम्नासाह
मभियोधानऽउत्सं।हरिंयत्तेमंदिनंदुक्षन्वृधे'गोरभसमद्रिभिर्वाताप्यं॥त्वमायसंप्रतिवर्त
योगो'र्दिवोऽअश्मानमुपनीतमृभ्वा।कुत्साययत्रपुरुहूतवन्व'ञ्छुष्णमनंतैःपरियासि ८४
वधैः॥पुरायत्सूरस्तमसोऽअपीते'स्तमद्रिवःफलिगंहेतिमस्य।शुष्णस्यचित्परिहितं

यदोजो'दिवस्परिसुघ्रथितंतदादः॥ २५ अनुत्वामहीपाजसीऽअचक्रे'द्यावाक्षामामदतामिंद्रक
र्मैन।त्वंवृत्रमाशयानंसिरासु'महोवज्रेणसिष्वपोवराहुं॥त्वमिंद्रनर्योयाँऽअवोनॄ'न्तिष्ठावातस्य
सुयुजोवहिष्ठान्।यंतेकाव्यऽउशनामंदिनंदा'द्वृत्रहणंपार्यंततक्षवज्रं॥त्वंसूरोहरितोरामयोनॄ'
न्भरच्चक्रमेतशोनायमिंद्र।प्रास्यपारंनवतिंनाव्यानामपिकर्तमवर्तयोयज्यून्॥त्वंनोऽअस्याऽ
इंद्रदुर्हणायाः'पाहिवज्रिवोदुरितादभीके।प्रनोवाजान्रथ्योऽअश्वबुध्या'निषेयंधिश्रव
सेसूनृतायै॥मासातेऽअस्मत्सुमतिर्विदसद्वाजप्रमहःसमिषोवरंत।आनोभजमघवन्गोष्व
र्यो'मंहिष्ठास्तेसधमादःस्याम॥ २६। १५। ९। १३५। अनु।त्वा।महीइति।पाजसी
इति।अचक्रेइति।द्यावाक्षामा।मदतां।इंद्र।कर्मन्।त्वं।वृत्रं।आऽशयानं।सिरासु।महः।वज्रे
ण।सिस्वपः।वराहुं।त्वं।इंद्र।नर्यः।यान्।अवः।नॄन्।तिष्ठ।वातस्य।सुऽयुजः।वहिष्ठान्।यं।ते।

संःप्र०८ काव्यः।उशना।मंदिनं।दात्।वृत्रऽहनं।पार्यं।ततक्ष।वज्रं।त्वं।सूरः।हरितः।रमयः।नृन्।भ
८५ रत्।चक्रं।एतशः।न।अयं।इंद्र।प्रऽअस्य।पारं।नवतिं।नाव्यानां।अपि।कर्तं।अवर्तयः।अय
ज्यून्।त्वं।नः।अस्याः।इंद्र।दुःऽहनायाः।पाहि।वज्रिऽवः।दुःऽइतात्।अभीके।प्र।नः।वाजान्।
रथ्यः।अश्वऽबुध्यान्।इषे।यंधि।श्रवसे।सूनृतायै।मा।सा।ते।अस्मत्।सुऽमतिः।वि।दसत्।
वाजऽप्रमहः।सं।इषः।वरंत।आ।नः।भज।मघऽवन्।गोषु।अर्यः।मंहिष्ठाः।ते।सधऽमादः।
स्याम। २६ इतिसंहिताप्रथमाष्टके अष्टमोध्यायः। इतिप्रथमाष्टकः समाप्तः।
श्रीकृष्णार्पणमस्तु॥

२ अग्निमीळे ९	२ अश्विना यं १२	२ आ त्वेता निषी १०	२ इंद्रं मित्राथि १०
२ वायवायाहि ९	२ सुरूपकृत्नुं १०	२ अंशुं दंति श्रेष्ठ ११	२ एंद्रसानसिं ११

८५

२ इंद्रेहि मत्स्वं १०
२ गायंति त्वा १२
१ इंद्रं विश्वा ८
२ अग्निं दूतं वृ १२
२ सुसमिद्धो न १२
२ ऐभिरग्ने दुवो १२
२ इंद्र सोमं पि १२
२ आ त्वा वहंतु ९
२ इंद्रा वरुण ९

२ सोमानं स्व ९
२ प्रति त्यं चा ९
३२ १९ १९४
२ अयं देवाय ८
१ इहेंद्राग्नी उ ६
४ प्रातर्युजा २१
५ तीव्राः सो २४
३ कस्य नूनं क १५
४ यच्चिद्धि ते २१

२ वसिष्वा हि १०
३ अश्वं न त्वा १३
२ यत्र ग्रावा पृ ९
१ यच्चिद्धि स ७
४ आ व ऽ इंद्रं क्रि २२
४ त्वमग्ने प्र १८
३ इंद्रस्य नु वी १५
३८ १३ १८९
३ एता या मो १५

२ त्रिश्चिन्नो अ १२
२ हृयाम्यग्निं ११
४ प्र वो यह्वं पु २०
३ क्रीळं वः श १५
३ कद्ध नूनं क १५
२ प्र यद्दित्था प १०
२ उत्तिष्ठ ब्रह्मण० ८
२ यं रक्षंति प्र ९
२ सं पूषन्न ध्व १०

सं·प्र·८

८६

२ कद्रुद्राय प्रचे ९
३ अग्ने विवस्व १४
२ त्वमग्ने वसूँरि १०
३ एषो उषा ऽअ १५
३५ १४ १७३
२ अयं वां मधु १०
३ सह वामेन १६
१ उषो भद्रेभि ४
२ उदु त्यं जातवे १३

३ अभि त्यं मेषं १५
३ त्यं सु मेषं म १५
२ न्यू३षु वाचं ११
२ मा नो ऽअस्मि ११
२ दिवश्चिदस्य ८
१ एष प्र पूर्वीर ६
१ प्र मंहिष्ठाय० ६
२ नू चित्सहोजा ९
१ वया ऽइदग्ने अ ७

१ वह्निं यशसं वि ५
३ अस्मा ऽइदु प्र १६
२९ १५ १५२
३ प्र मन्महे श १३
२ त्वं महाँ इन्द्र ९
३ वृष्णे शर्धाय १५
१ पश्वा न ता १०
१ रयिर्न चित्रा १०
१ वनेषु जायु १०

१ श्रीणन्नुप १०
१ शुक्रः शुशु १०
१ वनेम पूर्वीर ११
२ उप प्र जिन्व १०
२ नि काव्या वे १०
२ रयिर्न यः पि १०
२ उप प्रयंतो ९
१ जुषस्व सप्र० ५
१ का त ऽउपेति ५

८६

१कथादाशेमा ५	२प्रयेशुंभंतेज १२	३इमंस्तोमम १६	२इमांतेधियं ११
१अभित्वागो ५	२मरुतोयस्य १०	३३ १४ १६३	२तत्तऽइंद्रियंप ८
२हिरण्यकेशो १२	१प्रत्वक्षसःप्र ६	२द्वेविरूपेच ११	२योनिष्टऽइंद्र ९
३इत्थाहिसोम १६	१आविद्युन्मद्भि ६	२सप्रत्नथा ९	४चंद्रमाऽअ १९
३१ १९ १८५	२आनोभद्राः १०	१अपनःशो ८	१इंद्रंमित्रंव ७
२इंद्रोमदाय ९	२ऋजुनीतीनो ९	१वैश्वानरस्य ३	१यज्ञोदेवानां ३
१उपोषुशृणु ६	५त्वंसोमप्रचि २३	१जातवेदसे १	२यऽइंद्राग्नीचि १३
१अश्वावतिप्र ६	४एताऽउत्याऽउ १८	४सयोवृषा १९	२विह्यख्यंम ८
४असाविसो २०	२अग्नीषोमा १२	२प्रमंदिनेपि ११	२ततंमेऽअप ९

सं॰प्र॰८
८७

१ तक्षन्त्रथंसु ५
५ ईळेद्यावा१ २५
३२ १८ १७९
४ दूदंश्रेष्ठंज्यो २०
२ द्रुमारुह्मय ११
१ चित्रंदेवाना ६
५ नासत्याभ्यां २५
५ मध्वःसो २५
२ आवांरथो ११

२ आवांरथं १०
२ काराधद्धो १२
३ कदित्थानृं५ १५
२६ ० १३५
प्रथमाष्टकस्यवर्गाः
२६५ पंचरसाश्वि
नःसूक्तानि १२१
क्षितिनेत्रभुवःऋ
चः १३७० खमृ

ध्यग्निभुवः॥ ॥

८७

सं॰ग्र॰८
८८

इतिसंहिताप्रथमाष्टकसमाप्तः

८८

[OrderDescription]
,CREATED=23.07.20 10:44
,TRANSFERRED=2020/07/23 at 11:09:45
,PAGES=180
,TYPE=STD
,NAME=S0003352
,Book Name=M-2585-VYADHPADSMRITI
,ORDER_TEXT=
,[PAGELIST]
,FILE1=00000001.TIF
,FILE2=00000002.TIF
,FILE3=00000003.TIF
,FILE4=00000004.TIF
,FILE5=00000005.TIF

FILE6=00000006.TIF
,FILE7=00000007.TIF
,FILE8=00000008.TIF
,FILE9=00000009.TIF
,FILE10=00000010.TIF
,FILE11=00000011.TIF
,FILE12=00000012.TIF
,FILE13=00000013.TIF
,FILE14=00000014.TIF
,FILE15=00000015.TIF
,FILE16=00000016.TIF
,FILE17=00000017.TIF
,FILE18=00000018.TIF
,FILE19=00000019.TIF

FILE20=00000020.TIF
,FILE21=00000021.TIF
,FILE22=00000022.TIF
,FILE23=00000023.TIF
,FILE24=00000024.TIF
,FILE25=00000025.TIF
,FILE26=00000026.TIF
,FILE27=00000027.TIF
,FILE28=00000028.TIF
,FILE29=00000029.TIF
,FILE30=00000030.TIF
,FILE31=00000031.TIF
,FILE32=00000032.TIF
,FILE33=00000033.TIF

FILE34=00000034.TIF
,FILE35=00000035.TIF
,FILE36=00000036.TIF
,FILE37=00000037.TIF
,FILE38=00000038.TIF
,FILE39=00000039.TIF
,FILE40=00000040.TIF
,FILE41=00000041.TIF
,FILE42=00000042.TIF
,FILE43=00000043.TIF
,FILE44=00000044.TIF
,FILE45=00000045.TIF
,FILE46=00000046.TIF
,FILE47=00000047.TIF

FILE48=00000048.TIF
,FILE49=00000049.TIF
,FILE50=00000050.TIF
,FILE51=00000051.TIF
,FILE52=00000052.TIF
,FILE53=00000053.TIF
,FILE54=00000054.TIF
,FILE55=00000055.TIF
,FILE56=00000056.TIF
,FILE57=00000057.TIF
,FILE58=00000058.TIF
,FILE59=00000059.TIF
,FILE60=00000060.TIF
,FILE61=00000061.TIF

FILE62=00000062.TIF
,FILE63=00000063.TIF
,FILE64=00000064.TIF
,FILE65=00000065.TIF
,FILE66=00000066.TIF
,FILE67=00000067.TIF
,FILE68=00000068.TIF
,FILE69=00000069.TIF
,FILE70=00000070.TIF
,FILE71=00000071.TIF
,FILE72=00000072.TIF
,FILE73=00000073.TIF
,FILE74=00000074.TIF
,FILE75=00000075.TIF

FILE76=00000076.TIF
,FILE77=00000077.TIF
,FILE78=00000078.TIF
,FILE79=00000079.TIF
,FILE80=00000080.TIF
,FILE81=00000081.TIF
,FILE82=00000082.TIF
,FILE83=00000083.TIF
,FILE84=00000084.TIF
,FILE85=00000085.TIF
,FILE86=00000086.TIF
,FILE87=00000087.TIF
,FILE88=00000088.TIF
,FILE89=00000089.TIF

FILE90=00000090.TIF
,FILE91=00000091.TIF
,FILE92=00000092.TIF
,FILE93=00000093.TIF
,FILE94=00000094.TIF
,FILE95=00000095.TIF
,FILE96=00000096.TIF
,FILE97=00000097.TIF
,FILE98=00000098.TIF
,FILE99=00000099.TIF
,FILE100=00000100.TIF
,FILE101=00000101.TIF
,FILE102=00000102.TIF
,FILE103=00000103.TIF

FILE104=00000104.TIF
,FILE105=00000105.TIF
,FILE106=00000106.TIF
,FILE107=00000107.TIF
,FILE108=00000108.TIF
,FILE109=00000109.TIF
,FILE110=00000110.TIF
,FILE111=00000111.TIF
,FILE112=00000112.TIF
,FILE113=00000113.TIF
,FILE114=00000114.TIF
,FILE115=00000115.TIF
,FILE116=00000116.TIF
,FILE117=00000117.TIF

FILE118=00000118.TIF
,FILE119=00000119.TIF
,FILE120=00000120.TIF
,FILE121=00000121.TIF
,FILE122=00000122.TIF
,FILE123=00000123.TIF
,FILE124=00000124.TIF
,FILE125=00000125.TIF
,FILE126=00000126.TIF
,FILE127=00000127.TIF
,FILE128=00000128.TIF
,FILE129=00000129.TIF
,FILE130=00000130.TIF
,FILE131=00000131.TIF

FILE132=00000132.TIF
,FILE133=00000133.TIF
,FILE134=00000134.TIF
,FILE135=00000135.TIF
,FILE136=00000136.TIF
,FILE137=00000137.TIF
,FILE138=00000138.TIF
,FILE139=00000139.TIF
,FILE140=00000140.TIF
,FILE141=00000141.TIF
,FILE142=00000142.TIF
,FILE143=00000143.TIF
,FILE144=00000144.TIF
,FILE145=00000145.TIF

FILE146=00000146.TIF
,FILE147=00000147.TIF
,FILE148=00000148.TIF
,FILE149=00000149.TIF
,FILE150=00000150.TIF
,FILE151=00000151.TIF
,FILE152=00000152.TIF
,FILE153=00000153.TIF
,FILE154=00000154.TIF
,FILE155=00000155.TIF
,FILE156=00000156.TIF
,FILE157=00000157.TIF
,FILE158=00000158.TIF
,FILE159=00000159.TIF

FILE160=00000160.TIF
,FILE161=00000161.TIF
,FILE162=00000162.TIF
,FILE163=00000163.TIF
,FILE164=00000164.TIF
,FILE165=00000165.TIF
,FILE166=00000166.TIF
,FILE167=00000167.TIF
,FILE168=00000168.TIF
,FILE169=00000169.TIF
,FILE170=00000170.TIF
,FILE171=00000171.TIF
,FILE172=00000172.TIF
,FILE173=00000173.TIF

FILE174=00000174.TIF
,FILE175=00000175.TIF
,FILE176=00000176.TIF
,FILE177=00000177.TIF
,FILE178=00000178.TIF
,FILE179=00000179.TIF
,FILE180=00000180.TIF
,